THE MAHARAJA SAYAJIRAO UNIVERSITY OF BARODA

सत्यं शिवं सुन्दरम्

GAEKWAD'S ORIENTAL SERIES

No. 149

Gaekwad's Oriental Series

Published under the Authority of the Maharaja Sayajirao University of Baroda

General Editor:
B. J. Sandesara,
M.A., Ph.D.

No. 149

CATALOGUE OF PALM-LEAF MANUSCRIPTS IN THE ŚĀNTINĀTHA JAIN BHANDĀRA, CAMBAY

[PART TWO]

First Edition
Copies 500
1966

Published with the financial aid of the University Grants Commission and the Government of the Gujarat State.

Printed by Ramanlal J. Patel, Manager, The Maharaja Sayajirao University of Baroda Press (Sadhana Press), Near Palace Gate, Palace Road, Baroda and published on behalf of the Maharaja Sayajirao University of Baroda by Dr. Bhogilal J. Sandesara, Director, Oriental Institute, Baroda, February, 1966.

Price Rs. ~~24~~ 30/-

Copies can be had from :—

**THE UNIVERSITY PUBLICATIONS SALES UNIT,
Near Palace Gate, Palace Road,
BARODA**

CATALOGUE OF PALM-LEAF MANUSCRIPTS IN THE ŚĀNTINĀTHA JAIN BHAṆḌĀRA, CAMBAY

[PART TWO]

By

Āgama-Prabhākara

MUNI PUṆYAVIJAYA

Oriental Institute

BARODA

1966

FOREWORD

This is the second part of the Descriptive Catalogue of Palm-leaf Manuscripts in the Śāntinātha Bhaṇḍāra,* Cambay, prepared by Āgama Prabhākara Muni Śrī Puṇyavijayajī, after a personal scrutiny of each and every manuscript on the spot. Muni Śrī Puṇyavijayajī is a venerable doyen of Prākṛta and Jaina studies in India, who has devoted a whole life-time to the study and preservation of ancient manuscript-libraries and to the preparation of critical editions of numerous texts and has embarked upon the epoch-making project of preparing a critical edition of the whole of the Jaina Canon, a few volumes of which are already out.

Cambay or Stambhatīrtha of historical fame is famous for its manuscript-libraries, like Pāṭaṇ and Jaisalmer. The G. O. Series (No. 76) has already published a Catalogue of the Palm-leaf MSS in the Pāṭaṇ Bhaṇḍāra and another (No. 21) of the Jaina Bhaṇḍāra at Jaisalmer. Muni Śrī Puṇyavijayajī has now prepared a Classified Catalogue of all the MSS collected together from the various local Bhaṇḍāras in the Hemacandrācārya Jñānamaṇḍira at Pāṭaṇ as well as a fresh Descriptive Catalogue of all important MSS. in the various Bhaṇḍāras at Jaisalmer, and both the works will be shortly out through other agencies.

Śāntinātha Bhaṇḍāra is the most important MSS library at Cambay, but no such comprehensive attempt was made so far in respect of important literary material deposited there. A few MSS from the Bhaṇḍāra were referred to by Peterson and others in their Reports which are long out of print and not easily available. A short list of these MSS in Gujarātī script was published a few years back. The present publication was, therefore, a long-felt desideratum and we are very thankful to Muni Śrī Puṇyavijayajī for kindly consenting to publish this Descriptive Catalogue in the Gaekwad's Oriental Series. It needs hardly to be stated that the Praśastis and colophons of MSS described in such Catalogues are extremely interesting and useful, as they throw light on many facets of mediaeval history and culture and supply a wealth of information about the social and religious history of various sects, castes and families, and present invaluable materials for the study of place-names. Indices of the whole Descriptive Catalogue appended to this volume will be found useful and interesting from this point of view.

We are thankful to the University Grants Commission and the Government of Gujarat for jointly giving full financial aid towards the publication of this volume.

Oriental Institute,
Baroda
Dated 14th Feb. '66

B. J. SANDESARA,
Director

* The first part was published as G.O.S., no. 135 in 1961.

INTRODUCTION

The Śāntinātha Jñāna-bhaṇḍāra at Khambhāta is as important a library of ancient palm-leaf manuscripts written in the Devanāgarī script as those situated at Jesalmere, Pāṭaṇa, Ahmedabad, Surat, Poona and other places. These palm-leaf manuscript libraries are of great importance from the view-point of editing and studying such original texts as the Jaina Canons, the treatises on Jaina *Karmavāda*, the ancient story-literature in Sanskrit, Prakrit and Apabhraṃśa, the works on Indian philosophical systems, on Grammar and on lexicography, the *Kāvyas*, the *Nāṭakas*, treatises on rhetoric, the *Subhāṣitas* and so on.

Since they have preserved very old, and in many cases even the oldest extant, manuscripts of works on various subjects, the originality of these works is also retained therein and as such they are highly useful to the Researchers. Likewise, a number of manuscripts preserved therein are quite unique in the sense that no other copies of the works concerned are available anywhere else, which factor enhances all the more the importance of these collections. As such, they have furnished considerable rare and unknown literary material. To cite but a few noteworthy instances:

The huge *Jñānabhaṇḍāras* at Pāṭaṇa have presented to us such works as the *Viśeṣāvaśyakamahābhāṣya-svopajña-ṭīkā*, which was commenced by Jinabhadragaṇin and completed by *Vādigaṇimahattara* Koṭṭārya, the *Pañcasaṅgraha-svopajña-ṭīkā* by Candrarṣi Mahattara, the *Śataka-bṛhadbhāṣya* of Cakreśvarasūri, the *Dānādiprakaraṇa* by Sūrācārya; the latter half of the *Syādvāda-ratnākara* by Vādidevasūri, the *Hetubindu-ṭīkā* of Ācārya Dharmakīrti, the *Tattvopaplavasiṃha* by Jayarāśi, the *Pramāṇasaṅgraha* by the Digambara pontiff Akalaṅkadeva; the *Kahāvalī* of Bhadreśvarasūri, the *Davadantīcaritra* and the *Kalāvatīcaritra* in Prakrit, the *Paümasiricariu* in Apabhraṃśa by Dhāhila; the *Malayagiri-vyākaraṇa* and the *Mugdhabodhavyākaraṇa;* the *Līlāvaīkahā* in Prakrit by Kutūhalakavi, Someśvaradeva's *Vikramāṅkakāvya*, the *Sūktaratnākara*; the commentaries of Śrīkaṇṭha and Trivikrama Bhaṭṭa on the *Vṛttaratnākara*; Ājaḍa's commentary on the *Sarasvatīkaṇṭhābharaṇa*, the *Kaviśikṣā* by Vinayacandrasūri; the *Raghuvilāsa-nāṭaka* by Rāmacandra and the *Rūpakaṣaṭka* of Vatsarāja; Yogghama's commentary on the *Arthaśāstra* of Kauṭilya; the *Lakṣaṇasamuccaya* by Virocana, the commentaries *Cūḍāmaṇi* and *Līlāvatī* on the *Praśna-vyākaraṇa*, the *Cūḍāmaṇisāra*; the *Uktivyaktiprakaraṇa* and Vaijanātha's *Kalānidhi*.

Likewise, Jinabhadrasūri's Palm-leaf collection in the fort of Jesalmere has brought to light such valuable works as the *Daśavaikālikasūtra-cūrṇi* by Sthavira Agastyasiṃha, the *Jyotiṣkaraṇḍaka* by Pādaliptasūri along with a *Ṭippaṇa*,

Rāmadevagaṇin's *Ṭippaṇas* on both the *Saptatikā* and *Ṣaḍaśīti Karmagranthas*; the *Cauppannamahāpurisacariya* of Śīlāṅka, the *Ariṭṭhanemicariu* in Apabhraṃśa by Haribhadrasūri of the *Bṛhadgaccha*, the *Vilāsavaīkahā* in Apabhraṃśa by Siddhasenasūri Sādhāraṇa, the *Añjanāsundarīcaritra* by Guṇasamṛddhi Mahattarā, a nun of the Kharataragaccha; the *Sarvasiddhāntapraveśa*, the *Dravyālaṅkāra* of Rāmacandra and Guṇacandra, the *Pramāṇāntarbhāva* of Devabhadra and Yaśodeva, the two *Vṛttis* of the *Sāṅkhyakārikās*, the *Tattvasaṅgraha* with the *Pañjikā*, the *Nyāyāvatāra-vṛtti* along with the *Ṭippaṇa* by the nun Jñānaśrī, the highly correct ancient manuscript of the Second *Khaṇḍa* of the *Sanmatitarka-vṛtti* by Abhayadeva Tarkapañcānana, the *Nyāyamañjarīgranthibhaṅga* of Cakradhara, the *Pramālakṣmalakṣaṇa* by Buddhisāgarasūri, Abhayatilakagaṇin's *Pañcaprasthānavyākhyā* on *Gautamīyanyāyasūtra-bhāṣya-vārttika-tātparyavṛtti-tātparyapariśuddhi*; the *Buddhisāgara-vyākaraṇa*, Prabodhamūrtigaṇin's *Durgapadaprabodha* on the *Kātantravyākaraṇa*; *Jayadeva's Chandaḥśāstra* in Prakrit with the commentary of Harṣaṭa, *Kaisiṭṭhachandaḥśāstra* in Prakrit with the commentary of Gopāla Bhaṭṭa; the *Alaṅkāra-darpaṇa* in Prakrit, the *Kalpalatāvṛttipallavaśeṣa-viveka* by Ambāprasāda Mahāmātya, the *Abhidhāvṛttimātṛkā*; a manuscript of the *Haravijaya Mahākāvya* of Vāgīśvarāṅka Kavi Ratnākara dated 1228 V.S., Bilhaṇa's *Vikramāṅkacaritakāvya*; the *Candralekhāvijaya Prakaraṇa* of Devacandrasūri; and the *Kauṭilīya-Arthaśāstra-vṛtti*.

Similarly, the Palm-leaf collection at Khambhāta (Cambay) also has preserved certain works of great significance, amongst which may be enumerated the following:

The *Niḥśeṣasiddhāntaparyāya*, the *Yogaśataka* * of Haribhadrasūri, the *Kṣetrasamāsa-prakaraṇa* by Candrasūri; the *Strī-nirvāṇa[-mukti-]-kevali-bhukti-prakaraṇa-vṛtti*; the *Kahārayaṇakosa* by Devabhadrasūri, the *Ākhyānakamaṇikośa* by Nemicandrasūri along with the commentary of Āmradevasūri, Udayaprabhasūri's *Dharmābhyudaya-mahākāvya-Vastupālasaṅghavarṇana*; the *Parasūtrakadambaka* and *Uṇādigaṇasūtrapāṭha* for the *Kātantra-vyākaraṇa*, the *Liṅgānuśāsana* of Vāmana; Jayamaṅgala's *Kaviśikṣā*; the *Subhāṣitaratnakośa* of the Śaiva scholar Mummuṇideva, the *Lokasaṃvyavahārapravṛttikāvya-subhāṣitāvalī* and other *Sūktāvalīs* and *Subhāṣitakośas*; and the *Saṭparṇakagāthākośa* compiled by a Jaina *ācārya*.

In fact, considerable information regarding the authors as well as the then kings, ministers, prominent merchants and religious personages is preserved in the manuscripts of these collections—which type of information would never be found in comparatively modern manuscripts. To cite but a few instances to the point:

*A manuscript of the author's own commentary on this work is preserved in the Kharataragaccha Bhaṇḍāra at Māṇḍavī in the Kaccha district.

(1) All old as well as modern manuscripts of the *Nyāyapraveśapañjikā* mention Pārśvadevagaṇin as its author. The fact, however, that this Pārśvadevagaṇin was identical with Dhaneśvarasūri's disciple of that name who, after attainment of the status of a *Sūri*, became famous as Śrīcandrasūri, the esteemed author of a number of works, is known only from the *Praśasti* at the close of the palm-leaf manuscript of the *Pañjikā* preserved in a collection at Pāṭaṇa. (2) The *Praśasti* of Śāntisūri at the close of his *Pāiya-ṭīkā* on the *Uttarādhyayanasūtra* is not available in its complete form in the modern manuscripts, while it is quite complete in the old palm-leaf manuscripts. (3) The name of the author of the *Niḥśeṣasiddhāntaparyāya* as Candrakīrtisūri and his *Praśasti* are not found anywhere else than its manuscript in the Khambhāta collection numbered here as 87.

Moreover, the post-colophon entries of these ancient palm-leaf manuscripts furnish a good deal of information regarding social, political, cultural and religious conditions of the region concerned. As a rule, we get historical information regarding big dynasties especially from some well-known works. All the same, certain important historical material concerning some small ruling families is available from the post-colophon entries of these manuscripts—which material at times plays a significant part in the determination of the history of bigger dynasties.

Certain regional information is also gathered from these entries. For instance, the scribe's post-colophon entry at the close of a manuscript of the Prakrit *Pṛthvīcandracaritra*, dated V.S. 1212, deposited in the Khambhāta collection and numbered 214 in the present catalogue, has (p. 370) : '*Lāṭadeśamaṇḍale mahī-damunayor antarāle...*', which reference makes it evident that at that time the term *Lāṭa* was employed for the region between the (river) Mahī (in the north) and the (river) Damana, *i.e.*, modern Damaṇagaṅgā (in the south). Likewise, manuscript no. 232 of the Palm-leaf Jñāna-bhaṇḍāra at Jesalmere, entitled *Bhavabhāvanāprakaraṇasvopajñavṛtti*, which is dated V.S. 1240, bears references to the villages called Pādrā and Vāsada (situated respectively in the Baroda and Kheḍā districts of Gujarāt) in the following statements made in the post-colophon entry :

'*Āsīha bambhagacche*
padrauṛe *ambasāyavarasetṭhī* ।'

and

'**Vāsappayammi** *gāme*
saḍḍho bālappasāyanāmo tti ।'

In the same way, ms. no. 208 of the same collection, which is entitled *Pañcāśakaprakaraṇa saṭīka* was written at Jesalmere in the latter half of the twelfth century of the Vikrama Era. It is stated at the end of this ms. that

it had been broken off when Pālīnagara in Rājasthān was plundered and that the missing portions were re-written at Ajayameru (mod. Ajamer in Rājasthān) in V.S. 1207 in order to compensate for the damage.

These post-colophon entries sometimes help us in determining the date of certain authors. In this regard may be cited such an entry at the close of a ms. of the tenth Parvan of Hemacandra's *Triṣaṣṭiśalākāpuruṣacarita*, no. 189 of the present catalogue, with the help whereof the date of Sumati Sādhu, the author of the *Laghu-vṛtti* on the *Daśavaikālikasūtra*, can be decided. It informs us that the *Ṣaṇḍeragaccha* was started by Ācārya Śāntisūri who originally belonged to the *Añcalagaccha*, that this *ācārya* had a disciple named Yaśobhadrasūri who abstained from such *vikṛtis* as ghee, oil etc. from his very childhood, which fact was accepted by king Mūlarāja, and that Sumati Sādhu, the author of the *Daśavaikālika-laghu-vṛtti*, was a disciple of Kṣemarṣi who, on his part, was a disciple of this Yaśobhadrasūri. From this information we can conclude that Sumati Sādhu flourished in the eleventh century of the Vikrama Era. Likewise Bālacandrasūri's commentary on the *Vivekamañjarī Prakaraṇa* (no. 176 of the present catalogue; D.C. 1278 V.S.) refers to Āsaḍa's commentary on the celebrated poem *Meghadūta*.

These ancient manuscript-collections indeed supply significant information regarding a number of dynasties, families, *gacchas*, *ācāryas*, Hindu and Muslim sovereigns, ministers and wealthy personages as also about such celebrations as those of erection of temples, of installation of images and of conferring of the status of an *ācārya* upon certain worthy personages; and such information enhances the importance of these collections as well as of their detailed catalogues.

Pertaining to the Jñāna-bhaṇḍāra at Khambhāta, we may say that this collection was formed, at the instance of the Jaina preceptors especially of the *Tapāgaccha*, by placing together small collections traditionally handed down through generations of preceptors and certain manuscripts prepared—and certain purchased—at the instance of several *ācāryas*. It also contains a number of mss. prepared by scribes employed by the Jaina Saṅgha at Vijāpura (North Gujarāt).

To state a few peculiarities of this collection, a reference may at first be made to ms. no. 36 entitled *Mahāniśīthasūtra*. This ms., probably written in the thirteenth century of the Vikrama Era, was prepared by a scribe employed by a Jaina votary of the Khaḍāyatā caste. It appears from this fact that the Jaina faith had its followers in that caste also. It may be noted by the by that we do get references to certain Khaḍāyatā Jaina *ācāryas* in ancient *paṭṭakas*. Now-a-days there are no Jainas among the Khaḍāyatā vaṇik caste of Gujarāt.

Similarly, we learn from ms. no. 13 that Tapā Devendrasūri had recited the *Ṣaḍaṅga Āgamas* along with commentaries during his discourses at the place called Jaṅgharaḷa; while no. 20 (2) informs us that Āsadhara of the Ūkeśa family got erected a temple of the 24 Jinas at Śatruñjaya and also other Jina-temples at such places as Stambhatīrtha, Sojhīntraka, Kāvī, Ṭimbāpura, Hāthīndaṇa, Nagara, Aṇahillapura and Balāsara (= mod. Vaṇāsaṇa in north Gujarāt ?).

The following statement of no. 20 (5) reveals the fact that in ancient times also monks used to manage the *Jñāna-bhaṇḍāras*:

'Saṃvat 1478 varṣe vaiśālikaśiromaṇipūjya Pan. Śāntisundaragaṇipādaiḥ sarvaṃ citkośakāryaṃ gañjukasamāracanādi akāri Bhārukacchaśālāyām / Śrī-saṅghasya śubhaṃ bhavatu śrīcitkośena // Cha // Pan. Śāntisundaragaṇibhiś citkośagañjukasamāracanādikṛtyaṃ vidadhe // Śrīḥ //'

There is a reference to the year commencing with the month of Vaiśākha in ms. no. 64. Likewise, no. 70, a ms. of the *Pākṣikasūtra* and the *Oghaniryukti*, was prepared by one Khemasiṃha Śrāvaka; while no. 80 *viz.* Tilakācārya's commentary on the *Daśavaikālikasūtra*, was revised by one Māṇikyatilaka. The post-colophon entry of ms. no. 202 states that Dhanadāka installed a new *Mūlapratimā* in the temple of Ādinātha at Kāśahṛda (mod. Kāsandrā), while his descendent Ālhāka spent after the *ābharaṇa*, *ārātrika* and *maṅgaladīpa* of this Yugādideva; *vide:*

Kāśahṛde varanagare
Dhanadākenā''dināthajinabhavane ।
Mūlapratimā'bhinavā
'sthyāpyata śuddhena cittena ॥ 4 ॥

and

Ālhāko'rjitavittād
ābharaṇaṃ śrīyugādidevasya ।
Ārātrikaṃ ca maṅgala—
—dīpayutaṃ kārayāmāsa ॥ 11 ॥

The following statement from ms. no. 270 is also interesting:

Svārthaṃ pustikālekhanasya pratiṣedhānantaraṃ yaḥ ko'pi pustikāṃ lekhayati tena sarvasādhāraṇam eva lekhayitavye'ti vyavasthā ॥ *cha* ॥ *Ata idaṃ Nyāya-praveśaka-Nyāyāvatāraṭippanakapustikā abhinavalikhite'ti sarvagacchasādhāraṇā śrīmajjinasiṃhasūrīṇām* । *Śrīvīrasiṃhasūrīṇām* ।

It appears from these words that when objections were raised against allowing the use of copies of the canonical works to the followers of different *gacchas*, certain *Gītārtha* preceptors made it a rule that all the copies prepared thenceforth ceased to belong to any particular *gaccha* so that all could get the same for study without any difficulty.

Ms. no. 385 adds a lot to the importance of this collection inasmuch as this ms. of Udayaprabhācārya's *Dharmābhyudayamahākāvya*, containing in it a vivid description of Vastupāla's pilgrimage, was copied down in V. S. 1290 by the great minister Vastupāla himself. Similarly, no. 121 is a collection of seven small works such as *Subāhucaritra*, *Yogaśataka* and others copied by Śrāvikā Jñānadevī. We learn from this that in those days female votaries also could prepare such mss. in such nice hand-writings. In the same way, no. 142 is a manuscript of Maladhārī Hemacandra's commentary on the *Jīvasamāsa*, which is believed to be in the hand of the worthy commentator himself and this seems to be a fact in view of a close inspection of the *Puṣpikā*, the style and correctness of writing and the references made to wrong variants.

In short, the material that is presented by the Khambhāta collection is indeed valuable from the literary, historical and cultural points of view.

MUNI PUNYAVIJAYA

II

PRAKARANA SECTION (प्रकरण विभाग)

(Continued)

No. 121 (1) Subāhucaritra (१) सुबाहुचरित्र

Folios – 15
Language – Prakrit
Age of MS. – c. first half of the thirteenth century V. S.
Extent – Gāthās 228
Size – 14·5 × 1·7 inches
Condition – Good

आदिः—

॥ ॐ नमो वीतरागाय ॥

नमिऊण जिणं वीरं ससुरासुरमणुयइंदणयचलणं ।
वोच्छं सुबाहुचरियं गुरूवएसाणुसारेण ॥ १ ॥

अन्तः—

एयं सुबाहुचरियं गुणसुट्ठिएण धीरेण ता सुणवि तुम्हि ।
पत्तेसु दाणं विहुणा विहेह जिं लहह मोक्खमणंतसोक्खं ॥ छ ॥

सुबाहुचरितं समाप्तमिति ॥ छ ॥ लिखितं सावदेव्या सिवदेविनिमित्तं कर्मक्षयार्थं च ॥ छ ॥

(2) Śālibhadracaritra (२) शालिभद्रचरित्र

Folios – 15 to 25
Language – Prakrit
Age of MS. – c. first half of the thirteenth century V. S.
Extent – Gāthās 117.
Size – 14·5 × 1·7 inches
Condition – Good

आदिः—

सुरवरकयमाणं णट्ठणीसेसमाणं भवजलहिसुजाणं सत्तहत्थप्पमाणं ।
वियरियवरदाणं छिण्णकम्मारिताणं पयडियवरणाणं वंदिउं वद्धमाणं ॥ १ ॥

वोच्छामि सालिभद्दस्स पवित्तं वरमंगलं । चरियं सुयसमाइण्णं दाणप्फलपसंसियं ॥ २ ॥

अन्तः—

इय परमपवित्तं सालिभद्दस्स एयं, चरियमइविसिट्ठं जे पढंती मणुस्सा ।
तह य अणुगुणंती जे य वक्खाणयंती, नरसुरवरसुक्खं भुंजिउं जंति मुक्खं ॥७४॥

सालिभद्रचरितं समाप्तम् ॥ छ ॥

II

PRAKARANA SECTION (प्रकरण विभाग)

(Continued)

No. 121 (1) Subāhucaritra (१) सुबाहुचरित्र

Folios – 15
Language – Prakrit
Age of MS. – c. first half of the thirteenth century V. S.
Extent – Gāthās 228
Size – 14·5 × 1·7 inches
Condition – Good

आदिः—

॥ ॐ नमो वीतरागाय ॥

नमिऊण जिणं वीरं ससुरासुरमणुयइंदणयचलणं ।
वोच्छं सुबाहुचरियं गुरूवएसाणुसारेण ॥ १ ॥

अन्तः—

एयं सुबाहुचरियं गुणसुट्ठिएण धीरेण ता सुणवि तुम्हि ।
पत्तेसु दाणं विहुणा विहेह जिं लहह मोक्खमणंतसोक्खं ॥ छ ॥
सुबाहुचरितं समाप्तमिति ॥ छ ॥ लिखितं सावदेव्या सिवदेविनिमित्तं कर्मक्षयार्थं च ॥ छ ॥

(2) Śālibhadracaritra (२) शालिभद्रचरित्र

Folios – 15 to 25
Language – Prakrit
Age of MS. – c. first half of the thirteenth century V. S.
Extent – Gāthās 117.
Size – 14·5 × 1·7 inches
Condition – Good

आदिः—

सुरवरकयमाणं णट्ठणीसेसमाणं भवजलहिसुजाणं सत्तहत्थप्पमाणं ।
वियरियवरदाणं छिण्णकम्मारिताणं पयडियवरणाणं वंदिउं वद्धमाणं ॥ १ ॥
वोच्छामि सालिभद्दस्स पवित्तं वरमंगलं । चरियं सुयसमाइण्णं दाणप्फलपसंसियं ॥ २ ॥

अन्तः—

इय परमपवित्तं सालिभद्दस्स एयं, चरियमइविसिट्ठं जे पढंती मणुस्सा ।
तह य अणुगुणंती जे य वक्खाणयंती, नरसुरवरसुक्खं भुंजिउं जंति मुक्खं ॥७४॥

सालिभद्रचरितं समाप्तम् ॥ छ ॥

(3) Puṇḍarīkastava (३) पुण्डरीकस्तव

Folios – 25 to 33
Language – Prakrit
Author – Jiṇāyāsa
Age of MS. – c. first half of the 13th century V. S.
Extent – Gāthās 118.
Size – 14·5 × 1·7 inches
Condition – Good

आदिः—

॥ नमो सुयदेवयाए ॥

आरंभेसु नियत्ता सव्वट्ठाणेसु मुक्कवावारा ।
उच्छण्णरागदोसा ते देवा देवयाणं पि ॥ १ ॥

अंतः—

सेत्तुंजम्मि वजंतो दाणं जो देइ अत्थिओ पुरिसो ।
एयारिसो य लोए दाणवई दुल्लहो होइ ॥ ११४ ॥
पढमो जो य मणुस्सो संसारे दुक्खिओ दरिद्दो य ।
बीओ य सया सुहिओ माणुसजम्मे य सग्गे य ॥ ११५ ॥
नायाधम्मकहाओ सोऊण कहाणयं सुयहरेहिं ।
संखेवेण निबद्धा **सेत्तुंजकहा** य लोगम्मि ॥ ११६ ॥
वीयलंभायणेज्जो सुसाहुगुणपूयओ **जिणायासो** ।
तेण कहा निम्मविया **सेत्तुंजे** परम भत्तीए ॥ ११७ ॥
मा हवउ तस्स पावं **सारावलिपोत्थयं** लिहंतस्स ।
लहउ य जसो य कित्ती अइरेणं साहुसक्खारं ॥ ११८ ॥

पुंडरीकस्तवः परिसमाप्तः ॥

The work is also known as Śatruñjayakathā and Sārāvalī.

(4) Sukośalacaritra (४) सुकोशलचरित्र

Folios – 34 to 44
Language – Prakrit
Age of MS. – c. first half of the 13th cent. V.S.
Extent – Gāthās 108.
Size – 14·5 × 1·7 inches.
Condition –Good

आदिः—

अह एत्तो वीसइमे जिणंतरे वद्दमाणसमयंमि ।
विजओ नाम नरिंदो साएयपुराहिवो जाओ ॥ १ ॥

अन्तः—

एयं जो सुणइ नरो भावेण [illegible]

उवसग्गविप्पमुक्को लहइ य पुन्नप्फलं विउलं ॥ १०८ ॥ छ ॥

सुकोसलचरित्रं समाप्तं ॥ छ ॥

(5) Devakīcaritra—Devakīsutacaritra (५) देवकीचरित्र—देवकीसुतचरित्र

Folios – 44 to 55
Language – Prakrit
Age of MS. – c. first half of the 13th cent. V. S.
Extent – Gāthās 97.
Size – 14·5 × 1·7 inches
Condition – Good

आदिः—

नमिऊण चलणजुयलं **नेमि**जिणिंदस्स लोगनाहस्स ।
देवयसुयाण चरियं नामग्गहणं पवक्खामि ॥ १ ॥

अंतः—

इय **देवइसुयचरियं** जो पढइ सुणेइ जो उ भावेणं ।
सो पावइ परमफलं इहलोए उत्तमं सोक्खं ॥ ९७ ॥ छ ॥

देवइचरितं समाप्तं ॥ छ ॥

(6) Yogaśataka (६) योगशतक

Folios – 55 to 65
Language – Prakirt
Author – Haribhadrasūri
Age of MS. – c. first half of the 13th cent. V.S.
Extant – Gāthās 101.
Size – 14·5 × 1·7 inches
Condition – Good

आदिः—

नमिऊण जोगिनाहं सुजोगसंदंसगं **महावीरं** ।
वोच्छामि जोगलेसं जोगज्झयणाणुसारेण ॥ १ ॥

अन्तः—

ता इय आणाजोगे जइयव्वमजोगयत्थिणा सम्मं ।
एसो च्चिय **भवविरहो** सिद्धीए सया अविरहो य ॥ १०१ ॥

जोगसयं समत्तं ॥ छ ॥

(7) Ajitaśāntistava (७) अजितशान्तिस्तव

Folios – 65 to 72
Language – Prakrit
Author – Nandiṣeṇa
Age of MS. – c. first half of the 13th cent. V.S.
Extent – Gāthās 39
Size – 14·5 × 1·7 inches
Condition – Good

*

(2) Puṣpamālāprakaraṇa-Upadeśamālāprakaraṇa (२) पुष्पमालाप्रकरण-उपदेशमालाप्रकरण

Folios – 85 to 134
Language – Prakrit
Author – Maladhārī Hemacandrasūri
Age of MS. – c. Latter half of 13th cent. V. S.
Extent – Gāthās 505
Size – 14 × 1·5 inches
Condition – Fair

(3) Dharmākhyāna (३) धर्माख्यान

Folios – 134 to 138
Language – Prakrit
Age of MS. – c. Latter half of 13th cent. V. S.
Size – 14 × 1·5 inches
Condition – Fair

आदिः—

सिद्धं सिरिवच्छधरं उसभसिरिं परमरूवदेहधरं ।
वरनाणदंसणधरं वंदे वरसत्तिकित्तिधरं ॥ १ ॥

अन्तः— वोच्छं णिच्छयपच्छं जिणवयणामयसमुद्दणीसंदं ।
इणममयबिंदुसरिसं धम्मक्खाणं सुणह मज्झं ॥ १२ ॥

*

No. 125 (1) Upadeśamālāprakaraṇa (१) उपदेशमालाप्रकरण

Folios – 66
Language – Prakrit
Author – Dharmadāsa Gaṇi.
Age of MS. – c. beginning of 16th cent. V. S.
General Remarks – At several places the letters are worn out.
Extent – Gāthās 540
Size – 14 × 1·7 inches
Condition – Fair

(2) Śrāvakapratikramaṇasūtra–Vandittusūtra

(२) श्रावकप्रतिक्रमणसूत्र–वंदित्तुसूत्र

Folios – 67 to 73
Language – Prakrit
Age of MS. c. beg. of 16th cent. V. S.
General Remarks – At several places the letters are rubbed off.
Extent – Gāthās 50; Granthas 63
Size – 14 × 1·7 inches
Condition – Fair

(3) Bṛhacchāntistotra (३) बृहच्छान्तिस्तोत्र

Folios – 73 to 77
Language – Sanskrit
Author – Vādivetāl Śāntisūri
General Remarks – at several places the letters are rubbed off.
Age of MS. – c. beg. of 16th cent. V. S.
Size – 14 × 1·7 inches
Condition – Fair

(4) Śāśvatāśāśvatajinastavana (४) शाश्वताशाश्वतजिनस्तवन

Folios – 78 to 82
Language – Prakrit
Author – Siddhasenasūri
Age of MS. – c. beg. of 16th cent. V. S.
Extent – Gāthās 3 to 34.
Size – 14 × 1·7 inches
Condition – Fair
General Remarks – At several places letters are rubbed off; first two Gāthās are lacking.

आदिः—

................याणं तियसासुरसामिवंदियकमाणं ।
तित्थयराण तिहुयणे चेइयभवणे नमंसामि ॥ ३ ॥

अन्तः—

कित्तिम अकित्तिमा वि य तित्थयरा वंदिया सव्वे ।
जिणभवणेसु निविट्ठा साहारणभत्तिराएण ॥ ३३ ॥
भरहाइमणुयमहिया मोहारिमल्लमहियमाहप्पा ।
सिरिसिद्धसेणसूरीहिं संथुया सिवसुहं दिंतु ॥ ३४ ॥

(5) Duṣṣamagaṇḍikāprakaraṇa (५) दुष्षमगंडिकाप्रकरण

Folios – 82 to 94
Language – Prakrit
Age of MS. – c. beg. of 16th cent. V. S.
General Remarks – At several places letters have been rubbed off.
Extent – Gāthās 83; Granthas 103
Size – 14 × 1·7 inches
Condition – Fair

॥ ॐ नमो वीतरागाय ॥

आदिः—

नमिऊण जिणवराणं णिज्जियसमणाण णिम्ममत्ताणं ।
वोच्छं **दूसमगंडी** गुरूवएसाणुसारेण ॥ १ ॥

अंतः—

जह जह वड्ढइ कालो तह तह कुलरूवसीलदाणपरिवड्ढी ।
दो रयणीओ मणुया आरंभो जाव छ चेव ॥ ० ॥

दूसमगंडिका समाप्ता ॥ छ ॥

(6) Ekaviṃśatisthānaprakaraṇa (६) एकविंशतिस्थानप्रकरण

Folios – 94 to 103
Language – Prakrit
Author – Siddhasenasūri
Extent – Gāthās 65; Granthas 81.
Size – 14 × 1·7 inches

Age of MS. – c. beg. of 16th cent. V. S. Condition – Fair
General Remarks – At several places letters are worn out.

*

No. 126. (1) Upadeśamālāprakaraṇa (१) उपदेशमालाप्रकरण

Folios – 59 Extent – 543 Gāthās
Language – Prakrit Size – 13·2 × 2·2 inches.
Author – Dharmadāsagaṇi. Condition – Good
Age of MS. – c. First half of 14th cent. V. S.

(2) Sthavirāvalī–Nandīmaṅgala (२) स्थविरावली–नंदीमंगल

Folios – 59 to 65 Extent – Gāthās 50.
Language – Prakrit Size 13·2 × 2·2 inches
Author – Devavācaka Condition – Good
Age of MS. – c. First half of 14th cent. V. S.

(3) Catuśśaraṇaprakīrṇaka (३) चतुश्शरणप्रकीर्णक

Folios – 65 to 73 Extent – Gāthās
Language – Prakrit Size – 13·2 × 2·2 inches
Author – Vīrabhadragaṇi. Condition – Good
Age of MS. – c. First half of 14th cent. V. S.

(4) Ṛśimaṅḍalaprakaraṇa–Maharśikulaka

(४) ऋषिमंडलप्रकरण–महर्षिकुलक

Folios – 73 to 90 Extent – Gāthās 161
Language – Prakrit Size – 13·2 × 2·2 inches
Author – Dharmaghoṣasuri Condition – Good
Age of MS. – c. First half of 14th cent. V. S.

(5) Ajitaśāntistava (५) अजितशान्तिस्तव

Folios – 90 to 94 Extent – Gāthās 44
Language – Prakrit Size – 13·2 × 2·2 inches
Author – Nandiṣeṇa Condition – Good
Age of MS. – c. First half of 14th cent. V. S.

(6) Yogasaṅgrahagāthā (६) योगसंग्रहगाथा

Folios – 94 to 100 Extent – Gāthās 266.
Language – Prakrit Size – 13·2 × 2·2 inches
Age of MS. – c. First half of 14th cent. V. S. Condition – Good

(7) Ṛṣabhapañcāśikā (७) ऋषभपंचाशिका

Folios – 100 to 105 Extent – Gāthās 50.
Language – Prakrit Size – 13·2 × 2·2 inches
Author – Dhanapāla Condition – Good
Age of MS. – c. First half of 14th cent. V. S.

(8) Pravrajyāvidhāna (८) प्रव्रज्याविधान

Folios – 105 to 107
Language – Prakrit
Age of MS. – c. First half of 14th cent. V. S.
Extent – Gāthās 29.
Size – 13·2 × 2·2 inches
Condition – Good

(9) Bhayaharastotra (९) भयहरस्तोत्र

Folios – 107 to 109
Language – Prakrit
Age of MS. – c. First half of 14th cent. V. S.
Extent – Gāthās 22
Size – 13·2 × 2·2 inches
Condition – Good

(10) Praśnottararatnamālikā (१०) प्रश्नोत्तररत्नमालिका

Folios – 109 to 112
Language – Sanskrit
Author – Vimalācārya
Age of MS. – c. first half of the 14th cent. V.S.
Extent – Āryās 28.
Size – 13·2 × 2·2 inches
Condition – Good

(11) Pratikramaṇa-niryukti (११) प्रतिक्रमण-निर्युक्ति

Folios – 112 to 117
Language – Prakrit
Age of MS. – c. first half of the 14th cent. V.S.
Extent – Gāthās 51.
Size – 13·2 × 2·2 inches
Condition – Good

(12) Laghu Ajitaśāntistava (१२) लघुअजितशान्तिस्तव

Folios – 117 to 118
Language – Prakrit
Author – Vīragaṇi
Age of MS. – c. first half of the 14th century V. S.
Extent – Gāthās 8.
Size – 13·2 × 2·2 inches
Condition – Good

आदिः—

गब्भअवयारि सोहम्मसुरसामिउ, जणणि जे संथुणइ भत्तिभरभाविउ ।
ति जिण इक्खागकुलवंसभूसणधरा, अजिय संती य नंदंतु मंगलकरा ॥ १ ॥

अन्तः—

एव वच्छरि वि य पक्खीय चउमासए, अजियसंतित्थयं भणइ जो निसुणए ।
कहइ कविवीरगणि भवियजणअग्गए, असुह सवु जाइ सुह सयलु संपज्जए ॥८॥

लघुअजित[शान्ति]स्तवः समाप्तः ॥ छ ॥

(13) Bhaktāmarastotra (१३) भक्तामरस्तोत्र

Folios – 118 to 124
Language – Sanskrit
Author – Mānatuṅgasūri
Age of MS. – c. first half of the 14th cent. V.S.
Extent – Kāvyas 44.
Size – 13·2 × 2·2 inches
Condition – Good

(14) Samavasaraṇa from Āvaśyakaniryukti (१४) समवसरण–आवश्यकनिर्युक्तिगत

Folios – 124 to 129 Extent – Gāthās 71.
Language – Prakrit Size – 13·2 × 2·2 inches
Age of MS. – c. first half of the 14th cent. V. S. Condition – Good

*

No. 127 : (1) Dharmopadeśamālāprakaraṇa (१) धर्मोपदेशमालाप्रकरण

Folios – 33-39 Extent – Gāthās 100.
Language – Prakrit Condition – Good

आदिः—

सिज्झउ मज्झ वि सुयदेवि ! तुज्झ भरणाउ सुंदरा झत्ति ।
धम्मोवएसमाला विमलगुणा जयपडाय व्व ॥ १ ॥

अन्तः—

मइभेएण जमाली पुव्वग्गहियंमि हवइ गोविंदो ।
संसग्गि साग-भिक्खू गोट्ठामाहिल अभिनिवेसे ॥ १०० ॥ छ ॥

धम्मोवएसमालापगरणं समत्तं ॥

(2) Mahāvīracaritra (२) महावीरचरित्र

Folios – 39-47 Extent – Couplets 108.
Language – Apabhraṃśa Condition – Good
Author – Abhayadevasūri

आदिः—

ॐ नमो वर्द्धमानाय ॥

वीरजिणेसर वरचरिउ अइसयसयहिँ महंतु ।
आयन्निज्जउ कन्नसुहु सुयणहु वन्निज्जंतु ॥ १ ॥

णासियदोसासंगह अगणियगुणगणह, असुरसुरेसरविंदह वंदह कह जिणह ।
उम्मूलेइ अमंगलु मंगलु कुणइ लहु, सुहसंपय परिपोसइ झोसइ दुहनिवहु ॥ २ ॥

अंतः—

इय कल्लाणयकित्तणु किउ वीरह जिणह, पवर जिणेसरसूरिहिं सीसिं सुविहियह ।
अभयदेवसिरिसूरिं जिणगुणभावियह, होइ पढंतसुणंतह कारणु सिवसुहहं ॥ १०८ ॥
वीरचरियं समत्तं ॥ छ ॥

*

No. 128 : Dhyānaśataka ध्यानशतक

Folios – 143 to 156 Extent – Gāthās 105

Language – Prakrit
Size – 11.5 × 1.2 inches
Author – Jinabhadragaṇi Kṣamāśramaṇa
Condition – Good
Age of MS. – C. Latter half of 13th Cent. V. S.

आदिः—

वीरं सुक्कज्झाणग्गि दड्ढकम्मिंधणं पणमिऊणं ।
जोईसरं सरण्णं झाणज्झयणं पवक्खामि ॥

अन्तः—

इयसव्वगुणाहाणं दिट्ठादिट्ठसुहसाहणं झाणं ।
सुपसत्थं सद्धेयं णेयं झेयं च तिविहं पि ॥

पंचोत्तरेण गाहासएण [झाण] सययं समुद्दिट्ठं ।
जिणभद्दखमासमणेहिं कम्मसोहीकरं जइणो ॥

झाणसयं सम्मत्तं ॥ छ ॥

*

No. 129 (1) Pañcāśakaprakaraṇa (१) पंचाशकप्रकरण

Folios – 3 to 69
Size – 18 × 2.2 inches
Language – Prakrit
Condition – Good
Author – Ācārya Haribhadra
Age of MS. – c. Latter half of 14th Cent. V.S.
General Remarks – Upto the 18th Pañcāśaka.

अन्तः—

साधुविधिपंचाशकं समाप्तम् ॥ १८ ॥ छ ॥

(2) Upadhānavidhipañcāśaka Prakaraṇa.

(२) उपधानविधिपंचाशकप्रकरण

Folios – 69 to 77
Extent – Gāthās 50
Language – Prakrit
Size – 18 × 2.2 inches
Author – Abhayadevasūri(?)
Condition – Good
Age of MS. – c. Latter half of 14th Cent. V.S.

आदिः—

नमिऊण वद्धमाणं तवोविहाणं समासओ वोच्छं ।

अंतः—

कुग्गहविरहेणुज्जमह महह जइ मुक्खसुहमणहं ॥ ५० ॥
उवहाणपंचासयं सम्मत्तं ॥ छ ॥ श्रीम[द]भयदेवसूरेः कृतिरियं ॥ छ ॥

(3) Upadeśapadaprakaraṇa (३) उपदेशपदप्रकरण

Folios – 77 to 158
Language – Prakrit
Author – Haribhadrasūri
Age of MS. – c. Latter half of 14th Cent. V.S.

Extent – Gāthās 1040
Size – 18 × 2.2 inches
Condition – Good

आदिः—

नमिऊण महाभागं तिलोयनाहं जिणं महावीरं ।
लोयालोयमयंकं सिद्धं सिद्धोवएसत्थं ॥ १ ॥

अंतः—

जाइणिमयहरियाए रइता एते उ धम्मपुत्तेण ।
हरिभद्दायरिएणं भवविरहं इच्छमाणेण ॥ १०४० ॥

कृतिरियं श्रीहरिभद्रसूरेः ॥ छ ॥ शुभं भवतु लेखकस्य ॥

(4) Bṛhatsaṅgrahaṇīprakaraṇa (४) बृहत्संग्रहणीप्रकरण

Folios – 159 to 190
Language – Prakrit
Author – Jinabhadragaṇi Kṣamāśramaṇa
Age of MS. – c. Latter half of 14th Cent. V.S.

Extent – Gāthās 520.
Size – 18 × 2.2 inches
Condition – Good

आदिः—

निद्दवियअट्ठकम्मं वीरं नमिऊण तिगरणविसुद्धं ।

अन्तः—

जं उद्धियं सुयाओ पुव्वायरियकयमहव समईए ।
खमियव्व सुयहरेहिं तहेव सुयदेवयाए उ ॥ ५२० ॥

बृहत्संग्रहणी समाप्ता इति । भद्रं भवतु ॥ छ ॥ मंगलं महाश्रीः ॥

(5) Puṣpamālāprakaraṇa-Upadeśamālāprakaraṇa
(५) पुष्पमालाप्रकरण-उपदेशमालाप्रकरण

Folios – 191 to 223
Language – Prakrit
Author – Maladhārī Hemacandrasūri
Age of MS. – c. Latter half of 14th Cent. V.S.

Extent – Gāthās 505
Size – 18 × 2.2 inches
Condition – Good

आदिः—

सिद्धमकम्ममविग्गहमकलंकमसंगमक्खयं धीरं ।........

उवएसमालमेयं रएमि वरकुसुममालं व ॥ २ ॥

अंतः—

ताव पढिज्जउ एसा भव्वेहिं सया सुहत्थीहिं ॥ ५०५ ॥

हेमचन्द्रसूरिविरचितोपदेशमाला समाप्ता ॥ छ ॥

(6) Karmastavaprakaraṇa (Second Ancient Karmagrantha)

(६) कर्मस्तवप्रकरण (द्वितीय प्राचीन कर्मग्रन्थ)

Folios – 224 to 227 | Extent – Gāthās 57
Language – Prakrit | Size – 18 × 2.2 inches
Age of MS. – c. Latter half of 14th Cent. V.S. | Condition – Good

आदिः—

नमिऊण जिणवरिंदे तिहुयणवरनाणदंसणपईवे ।
बंधुदयसंतजुत्तं वोच्छामि थयं निसामेह ॥ १ ॥

अंतः—

दिसउ वरनाणलंभं दंसणसुद्धिं समाहिं च ॥ ५७ ॥

कर्मस्तवः समाप्तः ॥ छ ॥

(7) Karmavipākaprakaraṇa (First Ancient Karmagrantha)

(७) कर्मविपाकप्रकरण (प्रथम कर्मग्रंथ प्राचीन)

Folios – 224 to 227 | Extent – Gāthās 168
Language – Prakrit | Size – 18 × 2.2 inches
Author – Gargarṣi | Condition – Good
Age of MS. – c. Latter half of 14th Cent. V.S.

आदिः—

ववगयकम्मकलंकं वीरं नमिऊण कम्मगइकुसलं ।

अन्तः—

भणिओ **कम्मविवागो** समासओ **गग्गरिसिणा** उ ॥ ६७ ॥
जो गुरु पुच्छइ नाही **कम्मविवागं** तु सो अचिरा ॥ १६८ ॥

कर्मविपाकः समाप्तः ॥ छ ॥

(8) Śatakaprakaraṇa (Fifth Ancient Karmagrantha)

(८) शतकप्रकरण (पंचम कर्मग्रंथ प्राचीन)

Folios – 227 to 238 | Extent – Gāthās 111.

Language – Prakrit
Author – Śivaśarmasūri
Age of MS. – c. Latter half of 14th Cent. V.S.

Size – 18 × 2.2 inches
Condition – Good

आदिः—

अरहंते भगवंते अणुत्तरपरक्कमे पणमिऊणं ।
बंधसयगे निबद्धं संगहमिणमो पवक्खामि ॥ १ ॥

अन्तः—

इय कम्मपगडिपगयं संखेवुद्दिट्ठनिच्छयमहत्थं ।
जो उवउज्जइ बहुसो सो नाही बंधमोक्खत्थं ॥ १११ ॥

शतकप्रकरणं समाप्तम् ॥ छ ॥

(9) Saptatikāprakaraṇa (Sixth Karmagrantha)

(९) सप्ततिकाप्रकरण (षष्ठ कर्मग्रंथ)

Folios – 244 to 250
Language – Prakrit
Age of MS. – c. Latter half of 14th cent. V.S.

Extent – Gāthās 91.
Size – 18 × 2.2 inches
Condition – Good

आदिः—

सिद्धपएहिं महत्थं बंधोदयसंतपयडिठाणाणि ।

अंतः —

गाहाय सत्तरीए चंदमहत्तरमयाणुसारीए ।
टीकाए नियमियाणं संगहिया होइ नउईए ॥ ९१ ॥

सत्तरिया संमत्ता ॥ छ ॥

(10) Praśamaratiprakaraṇa (१०) प्रशमरतिप्रकरण

Folios – 250 to 270
Language – Sanskrit
Author – Umāswātī Vācaka
Age of MS. – c. Latter half of 14th cent. V. S.

Extent – Āryās 314
Size – 18 × 2·2 inches
Condition – Good

आदिः—

नाभेयाद्याः सिद्धार्थराजसूनुचरमाश्चरमदेहाः ।

अन्तः—

तस्मै वाचकमुख्याय नमो भूतार्थभाषिणे ॥ ३१४ ॥

॥ इति श्रीमदुमास्वातिवाचकविरचितं प्रशमरतिप्रकरणं समाप्तमिति भद्रं भवतु लेखक-पाठकस्य ॥ छ ॥

(11) Ekaviṃśatisthānaprakaraṇa (११) एकविंशतिस्थानप्रकरण

Folios – 270 to 274
Language – Prakrit
Author – Siddhasenasūri
Age of MS. – c. Latter half of 14th cent. V. S.

Extent – Gāthās 66
Size – 18 × 2·2 inches
Condition – Good

आदिः—

चवण विमाणा नयरी जणया जणणीउ रिक्खरासीओ ।

अन्तः—

इय एक्कवीसठाणा उद्धरिया सिद्धसेणसूरीहिं ।........॥ ६६

॥ एक्कवीसठाणाप्रकरणं समाप्तम् ॥ छ ॥

(12) Ṣaṭsthānakaprakaraṇa (१२) षट्स्थानकप्रकरण

Folios – 274 to 281
Language – Prakrit
Age of MS. – c. Latter half of 14th cent. V. S.

Extent – Gāthās 103.
Size – 18 × 2·2 inches
Condition – Good

आदिः—

कयवयकम्मयभावो सीलत्तं चेव तह य गुणवत्तं ।

अन्तः—

संतुट्ठसुप्पसन्नं भणइ सयं भाणइ परेणं ॥ १०३ ॥

॥ छट्ठाणाप्रकरणं समाप्तम् ॥ छ ॥

(13) Ātmānuśāsanaprakaraṇa (१३) आत्मानुशासनप्रकरण

Folios – 281 to 285
Language – Sanskrit
Age of MS. – c. Latter half of 14th cent. V. S.

Size – 18 × 2·2 inches
Condition – Good

आदिः—

सकलत्रिभुवनतिलकं प्रथमं देवं प्रणम्य सर्वज्ञम् ।

*

No. 130 Dharmopadeśamālāprakaraṇa धर्मोपदेशमालाप्रकरण

Folios – 78 to 86
Language – Prakrit
Age of MS. – c. Latter half of 13th cent. V. S.

Extent – Gāthās 101.
Size 13·5 × 2·2 inches
Condition – Good

*

No. 131 Rṣimaṇḍalastava ऋषिमंडलस्तव

Folios – 28 Extent – Gāthās 71

Language – Prakrit Size – 14·2 × 1·7 inches

Age of MS. – c. First half of 14th cent. V. S. Condition – Good

General Remarks – This work is different from that of the same name composed by Dharmaghoṣasūri.

आदिः—

इसिमंडलस्स गुणमंडलस्स तवनियममंडलधरस्स ।
संसारमंडलविघाडयस्स थयमुत्तमं वोच्छं ॥ १ ॥

जिणवरसासणनिउणा जिणवरवयणाणुरत्तभावेणं ।
सुणह सुकयत्थमिणं इसीसु इसिपालणा निच्चं ॥ २ ॥

भगवंतंमि य वीरे गोयमगोत्ते य इंदभूयंमि ।
धन्ने धम्मविहिन्ने जियलोभे अज्जलोभे य ॥ ३ ॥

अन्तः—

दसपुव्वधरं धीरं वंदे पवरबलविरियसंपन्नं ।
सव्वट्ठसिद्धिनिलयं तमहं वइरं नमंसामि ॥ ७७ ॥

एव मयमयणदोसरहिया मए सुरसहस्समहिया ।
रिसओ परिसाए दिन्तु बोहिं मज्झ य सिद्धिवसहिं उवविहिंतु ॥ ७१ ॥

रिसिमंडलस्तवः समाप्तः ॥ छ ॥

*

No. 132 (1) Pāpapratighātaguṇabījādhānasūtra-pañcasūtra-ādyasūtra

(१) पापप्रतिघातगुणबीजाधानसूत्र–पंचसूत्र–आद्यसूत्र

Folios – 1 to 3 Size – 13·7 × 2·5 inches

Language – Prakrit Condition – Good

Age of MS. – c. First half of 14th cent. V. S.

(2) Śrāvakapratikramaṇasūtra-Vandittusūtra

(२) श्रावकप्रतिक्रमणसूत्र–वंदित्तुसूत्र

Folios – 3 to 8 Extent – Gāthās 50

Language – Prakrit Size – 13·7 × 2·5 inches

Age of MS. – c. First half of 14th cent. V. S. Condition – Good

(3) Dharmalakṣaṇa (३) धर्मलक्षण

Folios – 8 to 9 Size – 13·7 × 2·5 inches

Language – Sanskrit
Condition – Good
Age of MS. – c. First half of 14th cent. V. S.

(4) Praśnottararatnamālikā (४) प्रश्नोत्तररत्नमालिका

Folios – 9 to 11
Extent – Āryās 28
Language – Sanskrit
Size – 13·7 × 2·5 inches
Author – Vimalācārya
Condition – Good
Age of MS. – c. First half of 14th cent. V. S.

(5) Kṣetrasamāsaprakaraṇa (५) क्षेत्रसमासप्रकरण

Folios – 11 to 17
Extent – Gāthās 88
Language – Prakrit
Size – 13·7 × 2·5 inches
Age of MS. – c. First half of 14th cent. V. S.
Condition – Good

(6) Vivekamañjarīprakaraṇa (६) विवेकमंजरीप्रकरण

Folios – 17 to 27
Extent – Gāthās 144
Language – Prakrit
Size – 13·7× 2·5 inches
Author – Āsaḍa
Condition – Good
Age of MS. – c. First half of 14th cent. V. S.
Date of Composition – V. S. 1248

(7) Bhavabhāvanāprakaraṇa (७) भवभावनाप्रकरण

Folios – 27 to 67
Extent – Gāthās 531
Language – Prakrit
Size – 13·7 × 2·5 inches
Author – Maladhārī Hemacandrasūri
Condition – Good
Age of MS. – c. First half of 14th cent. V. S.

(8) Kalyāṇamandirastotra (८) कल्याणमन्दिरस्तोत्र

Folios – 68 to 72
Extent – Kāvyas 44
Language – Sanskrit
Size – 13.7 × 2·5 inches
Author – Siddhasenadivākara
Condition – Good
Age of MS. – c. First half of 14th cent. V. S.

(9) Śrī Nemiḥ Pañcarūpa o Pañcamīstutiḥ
(९) श्रीनेमिः पंचरूप० पंचमीस्तुतिः

Folios– 72 to 73
Extent – Kāvyas 4
Language – Sanskrit
Size – 13.7 × 2·5 inches
Age of MS. c. First half of 14th cent. V. S.
Condition – Good

(10) Atiśayastavana (१०) अतिशयस्तवन

Folios – 73 to 74
Extent – Gāthās 13
Language – Prakrit
Size – 13.7 × 2·5 inches
Age of MS. – c. First half of 14th cent. V. S.
Condition – Good

(11) Vītarāgastotra (११) वीतरागस्तोत्र

Folios – 74 to 87
Language – Sanskrit
Author – Hemacandrācārya
Age of MS. – c. First half of 14th cent. V. S.
Extent – Granthas 187
Size – 13·7 × 2·5 inches
Condition – Good

(12) Ṛṣimaṇḍalaprakaraṇa (१२) ऋषिमंडलप्रकरण

Folios – 87 to 102
Language – Prakrit
Author – Dharmaghoṣasūri
Age of MS. – c. First half of 14th cent. V. S.
Extent – Gāthās 210
Size – 13.7 × 2·5 inches
Condition – Good

*

No. 133 (1) Ratnādevīśrāvikādvādaśavratagrahaṇasvarūpaprakaraṇa
(१) रत्नादेवीश्राविकाद्वादशव्रतग्रहणस्वरूपप्रकरण

Folios – 4
Language – Prakrit
Extent – Gāthās 82
Size – 13 × 1·7 inches
Condition – Good

आदिः—

संसारसिंधुत्तमजाणवत्तं वंदित्तु वीरं सिवठाणपत्तं ।
अंगीकरेमी जिणभासियाइं संमत्तजुत्ताइं गिहिव्वयाइं ॥ १ ॥
चोत्तीसबुद्धाइसयप्पहाणो पयत्तजीवाभयदाणताणो ।
पणट्ठअट्ठारसदोसठाणो देवोऽरिहं मज्झ अणंतनाणो ॥ २ ॥

अंतः—

एवं दुवालसविहो सिरिभद्दगुत्तो, सूरीण पायजुयलंमि गिहत्थधम्मो ।
अंगीकओ रतनदेविसुसावियाए, मोक्खत्थमेस जिणसासणभावियाए ॥ ८ ॥
सम्मत्तमूलो करुणालवालो वयत्थुडो चारुगुणोरुसालो ।
फलेउ सिक्खादलचक्कवालो मोक्खप्फलेणं गिहिधम्मसालो ॥ छ ॥
कत्थूरिगाकुंकुमचंदणाई पवालमुत्ताहलमाइ सव्वं ।
वज्जेमि फुल्लाणि तहेव अन्नं नेवोचियं जं विहवंगणाणं ॥
तहा जइस्सं दलइल्लयंमि लोहं तु लाभा० नदाव नयाविका ॥ १ ॥
विक्केमि नाहं मणुयं कयावि संवच्छरंतो तिरियाण तीसं ।
मोत्तूण हं बीयगिहाइकज्जं चित्तोवरिं नेव तिले धरिस्सं ॥ २ ॥

रज्जं महामच्चतभारहत्तं एमाइ वज्जेमि खरं तु कम्मं ।
उत्तारयाई नियमेमि पायं वित्तीइ छेए जयणा इमेसु ॥ ३ ॥
दुवालसेसुं चउपन्नएसुं १२५४गएसु वासाण सएसु माहे ।०
गएसु वासाण दुवालसेसुं सएसु बासट्ठहिएसु १२६२ किन्हे ।०
दुवालसेसुं चउताल१२४४वासाहियस्सएसुं निवविक्कमाओ ।
किण्हंमि पक्खे वरतेरसीए गुरुंमि वारे सुहकज्जसारे ॥
एसो दुवा०
जा सा चउत्थी वइसाहमासे तीए बुहम्मी अणुराहरिक्खे ।
अंगीकओ सिवसुहाण कए **सिरीयादेवीए** देवगुरुभत्तिपरायणाए ॥

(2) Chāḍāśrāvakadvādaśavratagrahaṇasvarūpaprakaraṇa

(२) छाडाश्रावकद्वादशव्रतग्रहणस्वरूपप्रकरण

Folios – 5 to 7
Language – Prakrit

Extent – Gāthās 66
Size – 13 × 1·7 inches
Condition – Good

आदिः—

संसारसिंधुत्तमजाणवत्तं वंदित्तु वीरं सिवठाणपत्तं ।
अंगीकरेमी जिणभासियाइं सम्मत्तजुत्ताइं गिहिव्वयाइं ॥ १ ॥
पयासियासेसविसेसजीवो भव्वाण अन्नाणतमप्पईवो ।
सुरासुरेहिं कयपायसेवो देवो जिणिंदो गयसव्वलेवो ॥ २ ॥

अंतः—

दुवालसेसुं निवविक्कमाओ सएसु वासेसु य सोलसेसु १२१६ ।
पक्खे सिए कत्तियमासि पक्खे कल्लाणजोगे दसमीतिहीए ॥ ६४ ॥
पुन्नो पवन्नो सिरि**माणतुंग**सूरीण मूलंमि गिहत्थधम्मो ।
छड्डाभिहाणेण सुसावएणं दुक्खक्खयत्थं सिवसोक्खहेऊ ॥ ६५ ॥
सम्मत्तमूलो करुणालवालो वयत्थुडो चारुगुणोरुसालो ।
फलेउ सिक्खादलचक्कवालो मोक्खप्फलेणं गिहिधम्मसालो ॥ ६६ ॥

परिग्रहप्रमाणं समाप्तमिति ॥ मंगलं महाश्रीः ॥ छ ॥

(3) Dvādaśavratagrahaṇasvarūpaprakaraṇa (३) द्वादशव्रतग्रहणस्वरूपप्रकरण

Folios – 8 to 11

Extent – Gāthās 39

Language – Prakrit

Size – 13 × 1·7 inches
Condition – Good

आदिः—

कल्लाणलच्छीण विलासगेहं वंदित्तु वीरं वरनाणदेहं ।
गिन्हामि सम्मं जिणदेसियाइं सम्मत्तजुत्ताइं गिहिव्वयाइं ॥ १ ॥
देवोऽरिहंतो सिवसुक्खकारी गुरू सुसाहू मम बंभयारी ।
जीवाइतत्तं जिणरायवुत्तं सम्मत्तमेयं गहियं पवित्तं ॥ २ ॥

अंतः—

बारसवरिससएसुं० ॥ ३७ ॥
एसो सावगधम्मो पासे सिरि०
पडिवन्नो मुक्खत्थं० सड्ढेणं० ॥ ३८ ॥
सम्मद्दंसणमूलो वयखंधो गुणविसालसाहालो ।
गिहिधम्मकप्परुक्खो सिवसुहफलओ लहुं होउ ॥ ३९ ॥ छ ॥

(4) Dvādaśavratagrahaṇasvarūpaprakaraṇa (४) द्वादशव्रतग्रहणस्वरूपप्रकरण

Folios – 11 to 12
Language – Prakrit

Extent – Gāthās 25
Size – 13 × 1·7 inches
Condition – Good

आदिः—

नमिऊण महावीरं गिन्हे सम्मत्तमणुवयाईयं ।
अरिहं देवो साहू गुरुणो तत्तत्थसद्दहणं ॥ १ ॥
थूलगपाणइवायं कन्नालियपभिइगोयरं अलियं ।
थूलमदत्तादाणं दुविहं तिविहेण वज्जेमि ॥ २ ॥

अंतः—

एगूणसट्ठे वरिसे भद्दवसियचउदसीइ इय धम्मो ।
ससिसूरिगुरुणा दिन्नो अमुगस्स सड्ढस्स ॥ २५ ॥

(5) Yaśomatīśrāvikādvādaśavratagrahaṇasvarūpaprakaraṇa

(५) यशोमतीश्राविकाद्वादशव्रतग्रहणस्वरूपप्रकरण

Folios – 13 to 14
Language – Prakrit

Extent – Gāthās 26
Size – 13 × 1·7 inches
Condition – Good

आदिः—

नमिऊण जिणं सम्मं वीरं पयडियसुसाहुगिहिधम्मं ।
सम्मत्तपुव्वयाइं गिहिव्वयाइं पवज्जामि ॥ १ ॥

अंतः—

रायाभिओगमाई अन्नत्थणाभोगपमुहआगारे ।
मुत्तूण इमे नियमा भंगे नियमाणअं विहियं ॥ २५ ॥

सिरिभद्दबाहुगणहरमूले बाहत्तरंमि इय धम्मो ।
जेट्ठसियपंचमीए जसमइसड्ढीए पडिवन्नो ॥ २६ ॥

(6) Śrāvakadvādaśavratagrahaṇasvarūpaprakaraṇa

(६) श्रावकद्वादशव्रतग्रहणस्वरूपप्रकरण

Folios – 15 to 16
Language – Prakrit
Extent – Gāthās 32
Size – 13 × 1·7 inches
Condition – Good

आदिः—

संसार सिंधु० । १ ॥ देवोऽरिहंतो० ॥ २ ॥

मिच्छं चउद्धा वि न भावणिज्जं संकातिमाई विचिगच्छपुव्वं ।
वंदे जिणिंदे दिवसेऽतिचारं संखेवओ विः प्पणिहाण........ ॥ ३ ॥

(7) Ṛṣabhajina–Vīrajina–Saptatyadhikaśatajinastuti

(७) ऋषभजिन–वीरजिन–सप्तत्यधिकशतजिनस्तुति

Folio – 15th
Language – Sanskrit
Extent – Kāvyas 12
Size – 13 × 1·7 inches
Condition – Good

(8) Caturviṃśatijinastuti (८) चतुर्विंशतिजिनस्तुति

Folio – 16th
Language – Sanskrit
Author – Bhadraguptasūri
Extent – Āryās 25
Size – 13 × 1·7 inches
Condition – Good

आदिः—

हेमाभ ! नाभिनंदन ! मरुदेवात्मज ! वृषांक ! ऋषभ ! जय ।
पंचधनुःशततनुचतुरशीतिलक्षामितपूर्वायुः ॥ १ ॥

अन्तः—

इति वर्ण्णमाननामायुरंकपितृमातृकीर्तनाज्जिनपाः ।
श्रीभद्रगुप्तसूरिभिरभिष्टुताः शिवसुखं दद्युः ॥ २५ ॥
मंगलं महाश्री ॥ छ ॥

(9) Vairāgyakulaka etc. (९) वैराग्यकुलक आदि

Folios – 17 to 19
Language – Prakrit
Size – 13 × 1·7 inches
Condition – Good

आदिः—

ता कइया तं सुदिणं सा सुतिही तं भवे सुनक्खत्तं ।
जम्मि सगुरुपरितंतो चरणभरधुरं धरिस्समहं ॥ १ ॥

अन्तः—

जह जह बंधइ नेहं पियपुत्तकलत्तामित्तबंधूहिं ।
तह तह खुप्पइ बहले संसारे दुक्खघोरंमि ॥ ॥ ३९ ॥ छ ॥

(10) Śrāvakadvādaśavratagrahaṇavidhiprakaraṇa
(१०) श्रावकद्वादशव्रतग्रहणविधिप्रकरण

Folios – 20 to 23
Language – Prakrit
General Remarks – Somewhat incomplete.
Extent – upto Gāthā 76
Size – 13 × 1·7 inches
Condition – Good

(11) Śrāvakadvādaśavratagrahaṇavidhiprakaraṇa
(११) श्रावकद्वादशव्रतग्रहणविधिप्रकरण

Folio – 24th
Language – Prakrit
Size – 13 × 1·7 inches
Condition – Good

*

No. 134 (1) Caityavandanavidhi [bhāṣya] prakaraṇa
(१) चैत्यवंदनविधि [भाष्य] प्रकरण

Folios – 143 to 147
Language – Prakrit
Age of MS. – c. First half of 14th cent. V. S.
Extent – Gāthās 40
Size 13 × 1·7 inches
Condition – Fair

आदिः—

वंदिय वीरजिणिंदं भणामि चियवंदणाविहिसरूवं ।
अहिगारसुद्दसंपयसहियं सुत्ताणुसाराओ ॥ १ ॥

अंतः—

इय नाऊण य सम्मं संपुन्नविहाणओ समाहीए ।
चीवंदणा विहेया बुहेहिं सय भव्वसत्तेहिं ॥ ४० ॥

चैत्यवंदनविधिः समाप्तः ॥ छ ॥

(2) Vandanakabhāṣya (२) **वंदनकभाष्य**

Folios – 147 to 151
Language – Prakrit
Author – Devendrasūri
Age of MS. – c. First half of 14th cent. V. S.
Extent – Gāthās 50
Size – 13 × 1·7 inches
Condition – Fair

आदिः—

नमिऊण महावीरं बाणउयसयं भणामि वंदणए ।
जह सुयहरेहिं भणियं भवियजणअणुग्गहट्ठाए ॥ १ ॥

अन्तः—

बाणउयसयसमेओ आवस्सगविही निदंसिओ एस ।
देविंदमुणिंदेहिं समासओ सुत्तनीईए ॥ ५० ॥

वंदनकभाष्यं समाप्तमिति ॥ छ ॥

(3) [Pratyākhyānabhāṣya] (३) **[प्रत्याख्यानभाष्य]**

Folios – 151 to 157
Language – Prakrit
Age of MS. – c. First half of 14th cent. V.S.
General Remarks – Incomplete.
Extent – Gāthās 62.
Size – 13 × 1·7 inches
Condition – Fair

आदिः—

नवकार पोरसीए पुरिमड्ढेकासणेयठाणे य ।
आयंबिलऽभत्तट्ठे चरिमे य अभिग्गहे विगई ॥ १ ॥

(4) Abhayapṛcchānāmaprakaraṇa (४) **अभयपृच्छानामप्रकरण**

Folios – 160 to 161
Language – Sanskrit
Age of MS. – c. First half of 14th cent. V. S.
Extent – Grantha 67.
Size – 13 × 1·7 inches
Condition – Fair
General Remarks – contains only *Ślokas* 55 to 67 of the Prakaraṇa. Incomplete.

अन्तः—

उन्मार्गदेशको यस्तु मिथ्यादृष्टिरसंगतः ।
वर्णवादी च साधूनां मुह्यते तेन कर्मणा ॥ ६५ ॥

एषोऽर्थो यथा दृष्टो जिनेंद्रैर्ज्ञानचक्षुषा ।
तथा मयाऽपि चाख्यातः संसारस्थेषु जंतुषु ॥ ६६ ॥
इदं विचित्रार्थपदोपशोभितं समीक्ष्य बुद्ध्या समुपेत्य संयमं ।
तपोभिनिर्नाशितकर्मसंचयः स सिद्धिमध्यासयते ह्यनुत्तराम् ॥ ६७ ॥

॥ **अभयपृच्छानामप्रकरणं समाप्तम्** ॥ मंगलं महाश्रीः ॥

(5) Subhāṣitasaṅgraha (५) **सुभाषितसंग्रह**

Folios – 162 to 167
Language – Sanskrit
Age of MS. – c. First half of 14th cent. V. S.
General Remarks – Folios 168–169 missing.
Extent – Kāvyas 74
Size – 13 × 1·7 inches
Condition – Fair

आदिः—

अमलिनपक्षद्वितयः सुपदन्यासेनं मंडयन् भूमिम् ।
हंस इव निर्मलात्मा कस्य न सुजनो मनो हरति ॥ १ ॥

(6) Dharaṇoragendrastotra (६) **धरणोरगेन्द्रस्तोत्र**

Folios – 171 to 174
Language – Sanskrit
Age of MS. – c. First half of 14th cent. V. S.
Extent – Granthas 36
Size – 13 × 1·7 inches
Condition – Fair

आदिः—

धरणोरगन्द्रसुरपेतिविद्याधरपूजितं जिनं नत्वा ।
क्षुद्रोपद्रवशमनं तस्यैव महास्तवं वक्ष्ये ॥ १ ॥

अन्तः—

भक्तिर्जिनेश्वरे यस्य गंधमाल्यानुलेपने ।
संपूजयति यश्चैनं तस्यैतत्सफलं भवेत् ॥ ३६ ॥

इति पार्श्वनाथफणिपतिधरणेंद्रस्तवनं समाप्तमिति ॥ छ ॥ मंगलं महाश्रीः ॥ छ ॥

(7) Pārśvastava (७) **पार्श्वस्तव**

Folios – 174 to 176
Language – Sanskrit
Author – Indranandi
Age of MS. – c. First half of 14th cent. V. S.
Extent – Kāvyas 9
Size – 13 × 1·7 inches
Condition – Fair

अन्तः—

झंकारं रांतयुक्तं शिखिपवनपुरःस्थापितं नामगर्भं

पश्यंतं यत्प्रभावाद्विजहति पुरुषं योगिनीमुद्रया द्राक् ।
रोँ ह्राँ ग्राँ हूँ फुट्प्राक्षरजपितजवैस्ताडितं शास्त्रगंधं
शाकिन्यः श्रीन्द्रनंदिः प्रथितगतिरसौ पातु मां पार्श्वनाथः ॥ ९ ॥

पार्श्वनाथस्तवः समाप्तः ॥ छ ॥

(8) Mahādevalakṣaṇa–Mahādevastotra (८) महादेवलक्षण–महादेवस्तोत्र

Folios – 176 to 179
Language – Sanskrit
Author – Hemacandrācārya
Age of MS. – c. First half of 14th cent. V. S.
Extent – Granthas 33
Size – 13 × 1·7 inches
Condition – Fair

आदिः—प्रशान्तं दर्शनं यस्य सर्वभूताभयप्रदम् ।

(9) Ātmānuśāsana (९) आत्मानुशासन

Folios – 179 to 185
Language – Sanskrit
Author – Pārśvanāga
Age of MS. – c. First half of 14th cent. V. S.
Extent – Granthas 77
Size – 13 × 1·7 inches
Condition – Fair
Date of Composition – 1042 V. S.

(10) Gaṇitagrantha (१०) गणितग्रन्थ

Folios – 186 to 188
Language – Sanskrit
Age of MS. – c. First half of 14th cent. V. S.
General Remarks – Incomplete
Extent – Ślokas 42
Size – 13 × 1·7 inches
Condition – Fair

आदिः—

मूडस्स य चत्तं मुडं कलसीमुले विसोअया दूणा ।
कुडवस्स य चउहाओ सेइमाणाण सो नाओ ॥ १ ॥
मूटकमूल्यद्रमार्द्धा रूपकाः कलसीभृतौ ।
तदर्द्धाः कलसीकार्द्धे तदर्द्धाः कुडवे मताः ॥ २ ॥

(11) Sarpaviṣāpahārauṣadhastotra with commentary
(११) सर्पविषापहारौषधस्तोत्र सटीक

Folios – 189 to 191
Language – Prakrit and Sanskrit
Author & Commentator – Śaṅkuka & Brahmaśambhu
Size – 13 × 1·7 inches
Condition – Fair
Age of MS. – c. First half of 14th cent. V. S.

आदिः—

श्रीब्रह्मशंभुनाचार्येण श्रीशंकुकगारुडशास्त्रोपरि विरचितटीकायां स्थावरजंगम-विषापहारार्थं उद्धरित औषधी अगदानां प्रयोगः ।

नाया वि फणिज्जयसुअरिसणाए मूलेण डंडुहायंति ।
अरुणोयरवरिसासंभवस्स वालक्कछीरेण ॥ १ ॥

दुंदुभा भवंति, के ते? नागा अपि, केन? फणिज्जकसुदर्शना चक्रांका, तथा अरुणोयरं, तंदुलीयकं वर्षासंभवा वैशाखकः पुनर्नवा स एव कथ्यते। तदेतेषां मूलेन नागा दुंदुभा भवंति। दष्टाश्च पानेन निर्विषा ज्ञातव्याः। तथा बालको मलार्कः क्षीरेण च कृतहस्त-लेपनेन नागा दुंदुभाः दंशस्थानमर्द्दनेन च दष्टाश्च निर्विषा भवंतीत्यर्थः ॥ छ ॥

सामलया गोहाई तिसूलिया मोरचूलिया चलणा ।
पीया नासंति विसं जह वट्टियभुयगडक्काण ॥ २ ॥

अन्तः—

दोवयणचम्ममढिया ढक्का सिहिनलयवाइया कुणइ ।
कीरतरुमूलघडिया णायाणुच्चाडणं सुइरं ॥ छ ॥

कीरतरुः शिरीषवृक्षस्तस्य मूलेन घटिता द्विवदनसर्पचर्मणा मढिता शिखिपिच्छ-नलकवादिता सती ढक्का सर्पाणामुच्चाटनं सुचिरं करोतीत्यर्थः ॥ छ ॥ इत्यगदानि ॥ छ ॥

संखाहुली गिरिनई अंधाहुली नाइ ।
लक्खसहस्सेहि वेढियउ पिउ दिक्खंतह जाइ ॥ छ ॥

*

No. 135 Bhavabhāvanāprakaraṇa भवभावनाप्रकरण

Folios – 101 to 168
Language – Prakrit
Author – Maladhārī Hemacandrasūri
Age of MS. – c. First half of 14th cent V. S.

Extent – Gāthās 531
Size – 13·2 × 1·7 inches
Condition – Good

*

No. 136 Śrāvakaprajñapti श्रावकप्रज्ञप्ति

Folios – 75 to 142
Language – Prakrit
Author – Umāswātivācaka

Extent – Gāthās 405
Condition – Good
Age of MS. – c. Beg. of 14th cent. V. S.

No. 137 Sādhuśrāvakasāmācārī साधुश्रावकसामाचारी

Folios – 124
Language – Prakrit–Sanskrit
Age of MS. – c. First half of 14th cent. V. S.
Size – 13·5 × 1·7 inches
Condition – Good
General Remarks – Incomplete

आदिः—

॥ ॐ नमो वीतरागाय ॥

नमिऊण तिलोयगुरुं लोयालोयप्पयासयं वीरं ।
विब्भमविणासहेतुं णुट्ठाणविधिं पवक्खामि ॥ १ ॥

तत्थाईए संमत्तारोवणविही भण्णइ । पसत्थे खेत्ते जिणभवणादिए पसत्थेसु तिहिकरणनक्खत्तमुहुत्तचंदबलेसु परिक्खियगुणं सीसं विसिट्ठकयनेवत्थं चंदणकयभालटिक्कयं करधरियखयफलं तिपयाहिणीकयसमोसरणं सूरी अग्गओ काउं खमासमणदाणपुव्वं भणावेइ । संमत्ताइ सामाइयतिगस्स आरोवणत्थं मम वासे खिवेह ।

*

No. 138 (1) Dhyānasvarūpādi (१) ध्यानस्वरूपादि

Folios – 2 to 7
Language – Sanskrit
Age of MS. – c. First half of 13th cent. V. S.
Size – 13·5 × 2 inches
Condition – Good
General Remarks – Folios 1 and 8 are missing.

(2) [Nakṣatraviṃśatikā] (२) [नक्षत्रविंशतिका]

Folios – 8 to 10
Language – Prakrit
Age of MS. – c. First half of 13th cent. V. S.
General Remarks – Folio 8 missing.
Extent – Gāthās 21
Size – 13·5 × 2 inches
Condition – Good

आदिः—

उत्तरतियं च मूलं हत्थो चित्ता य रेवई साई ।
अस्सिणिसहियारिक्खो रविवारे सिद्धिजोगो उ ॥ १ ॥

अन्तः—

हत्थो चित्ता भरणी रोहिणि तह फग्गुणी य असलेसा ।
तियसाढ पुव्वभद्दा सणिवारे असुह नव रिक्खा ॥ २१ ॥

(3) Śakunasaptatriṃśikā (३) शकुनसप्तत्रिंशिका

Folios – 11 to 13
Extent – Gāthās 37

Language – Prakrit
Author – Siddhapaṇḍita
Age of MS. – c. First half of 13th cent. V. S.

Size – 13·5 × 2 inches
Condition – Good

आदिः—

निशांत्यप्रहरस्यार्द्धादर्द्धयामावधिर्भवेत् ।
दग्धा प्रज्वलिता धूम्रा दिगीशान्यादितः क्रमात् ॥ १ ॥

अन्तः—

वसंतराजप्रभृतीन्यशेषाण्यालोक्य शास्त्राणि महोद्यमेन ।
चकार सिद्धः शकुनोत्तमानां विनिर्णयं शिष्टजनस्य तुष्ट्यै ॥ ३७ ॥
शकुनसप्तत्रिंशिका समाप्ता ॥ मंगलं महाश्रीः ॥ छ ॥

(4) Tapovidhi (४) तपोविधि

Folios – 13 to 15
Language – Prakrit
Age of MS. – c. First half of 13th cent. V. S.

Size – 13·5 × 2 inches
Condition – Good

(5) Āvaśyakasūtra (५) आवश्यकसूत्र

Folios – 16 to 19
Language – Prakrit
Age of MS. – First half of 13th cent. V. S.

Size – 13·5 × 2 inches
Condition – Good

(6) Lūṇa and Ārātrika Uttāraṇavidhi (६) लूण-आरात्रिक उत्तारण विधि

Folios – 19 to 20
Language – Prakrit
Age of MS. – c. First half of 13th cent. V. S.

Size – 13·5 × 2 inches
Condition – Good

(7) [Bhāvanāprakaraṇa] (७) [भावनाप्रकरण]

Folios – 21 to 24
Language – Prakrit
Age of MS. – c. First half of 13th cent. V. S.

Extent – Gāthās 43
Size – 13·5 × 2 inches
Condition – Good

आदिः—

नमिऊण नेमिनाहं तियसिंदनरिंदवंदियं सिरसा ।
संखेवओ महत्थं भावणसत्थं पवक्खामि ॥ १ ॥

अंतः—

खमह महं भो सुयणा अहियं च जणस्य (ऊणं च) जं मए रइयं ।
तं सोऊण व सव्वे करेह जह सोहणं होइ ॥ ४३ ॥

(8) [Bhāvanākulaka] (८) [भावनाकुलक]

Folios – 25 to 26
Language – Prakrit
Age of MS. – c. First half of 13th cent. V. S.
Extent – 23 Gāthās
Size – 13·5 × 2 inches
Condition – Good

आदिः—

संसारविसमसायरभवजलवडियाण संसरंताणं ।

अन्तः—

खणभंगुरे असारे मणुअभवे अब्भपडलसारिच्छे ।
सारं इत्तियमित्तं जं कीरइ सोहणो धम्मो ॥ २३ ॥ छ ॥

(9) Paccakkhāṇa (९) पच्चक्खाण

Folios – 26 to 28
Language – Prakrit
Age of MS. – c. First half of 13th cent. V. S.
Size – 13·5 × 2 inches
Condition – Good

(10) Caityavandanāsvarūpagāthā (१०) चैत्यवंदनास्वरूपगाथा

Folios – 29 to 31
Language – Prakrit
Age of MS. – c. First half of 13th cent. V. S.
Extent – Gāthās 26
Size – 13·5 × 2 inches
Condition – Good

(11) Pratyākhyānasvarūpagāthā (११) प्रत्याख्यानस्वरूपगाथा

Folios – 31 to 36
Language – Prakrit
Age of MS. – c. First half of 13th cent. V. S.
Extent – Gāthās 51
Size – 13·5 2 inches
Condition – Good

(12) Vandanakasvarūpagāthā (१२) वंदनकस्वरूपगाथा

Folios – 36 to 38
Language – Prakrit
Age of MS. – c. First half of 13th cent. V. S.
Extent – Gāthās 24
Size – 13·5 × 2 inches
Condition – Good

(13) Caturviṃśatijinastotra (१३) चतुर्विंशतिजिनस्तोत्र

Folios – 39 to 44
Language – Prakrit
Age of MS. – c. First half of 13th cent. V. S.
Extent – Kāvyas 24
Size – 13·5 × 2 inches
Condition – Good

(14) Sakalārhatstotra (१४) सकलार्हत्स्तोत्र

Folios – 45 to 47
Language – Sanskrit
Author – Hemacandrācarya
Age of MS. – c. First half of 13th cent. V. S.
Extent – Granthas 26
Size – 13·5 × 2 inches
Condition – Good

(15) Śāntijināṣṭaka (१५) शांतिजिनाष्टक

Folios – 48 to 49
Language – Prakrit
Age of MS. – c. First half of 13th cent. V. S.
Extent – Gāthās 8
Size – 13·5 × 2 inches
Condition – Good

(16) Prabhātakulaka (१६) प्रभातकुलक

Folios – 49 to 50
Language – Sanskrit
Age of MS. – c. First half of 13th cent. V. S.
Extent – Granthas 13
Size – 13·5 × 2 inches
Condition – Good

आदिः—

प्रातरेव समुत्थाय तीर्थनाथ मुखं तव ।
ये पश्यंति प्रणश्यंति तेषां नियतमापदः ॥ १ ॥

अंतः—

एतत् प्रभातकुलकं पुलकं दधानो यस्ते निशांतमुपगम्य निशांत एव ।
स्वामिन् पठेत् त्रिदिवि वासमुपास्य पश्चाच्चन्द्रप्रभामलमुपैति पदं स मुक्तेः ॥ १३ ॥

प्रभातकुलकस्तोत्रम् ॥

*

No. 139 Pañcasaṅgrahadīpaka-Ślokabandha पंचसंग्रहदीपक–श्लोकबंध

Folios – 104
Language – Sanskrit
Author – Bāmideva
Age of MS. – c. First half of 13th cent. V. S.
Extent – Granthas 1175
Size – 9·7 × 2·5 inches
Condition – Good
General Remarks – Folios 102-3 missing.

आदिः—

॥ ॐ नमः सर्वज्ञाय ॥ छ ॥

सिद्धं शुद्धं जिनाधीशं **नेमीशं** गुणभूषणम् ।
नत्वा ग्रंथं प्रवक्ष्यामि **पंचसंग्रहदीपकम्** ॥ १ ॥
नेमिचंद्रमुनीन्द्रेण यः कृतः **पंचसंग्रह** ।
स एव श्लोकबंधेन प्रव्यक्तीक्रियते मया ॥ २ ॥
बंधको बध्यमानं च बंधभेदास्तथेशता ।
हेतवश्चेति पंचानां संग्रहोऽत्र प्रकाश्यते ॥ ३ ॥

यस्तत्र बंधको जीवः सदसत्कर्मणां स्वयम् ।
तत्स्वरूपप्रकाशाय विंशतिः स्युः प्ररूपणाः ॥ ४ ॥

गुणा जीवाश्च पर्याप्तिप्राणसंज्ञाश्च मार्गणाः ।
उपयोगसमायुक्ता भवंत्येता प्ररूपणाः ॥ ५ ॥

मार्गणागुणभेदाभ्यां भवतो द्वे प्ररूपणे ।
मार्गणांतर्गताः शेषाः जीवमुख्याः प्ररूपणाः ॥ ६ ॥ छ ॥

पत्र ६५—

यद्ग्रंथश्रेणिवेणीललितपदगतिप्रोल्लसद्भूरिभाव-
प्रव्यक्ता....र्थसार्थप्रकटितसहजस्फारसार........ ।
तं वंदे योगिवंद्यं जिनपतिवदनांभोजानिर्यद्रहस्यं
सस्यं त्रैलोक्यकीर्त्तिं गुणमणिनिचयं येन विज्ञायि ॥

श्रीमानसौ जगति नंदतु भव्यबंधु**र्नेमिः** कलानिधिरुदारगुणैकधामा ।
यत्कीर्तिनिर्मलकलाव........कः सांको बभूव भुवनेष्विति सुप्रसिद्धम्
॥ ८२५ ॥ छ ॥

इति **श्रीद्रवामिदेव**विरचिते **पुरवाटवंशविशेषकश्रीनेमिदेवस्य** यशःप्रकाशके **पंचसंग्रहदीपके** बंधकस्वरूपप्र[रूपणो नाम] प्रथमोऽधिकारः ॥ छ ॥ * ॥ शुभं भवतु चतुर्विधसंघस्य ॥ छ ॥

पत्र ७७—

इत्युक्तं बध्यमानस्य कर्माष्टकस्य लक्षणम् ।
मूलोत्तरप्रभेदेन यथोक्तं पूर्वसूरिभिः ॥ १४० ॥
यः कर्मप्रकृतिस्थितिव्यतिकरव्याख्यानदीक्षागुरु-
र्यश्चारित्रमहार्णवावधिगतो रत्नत्रयालंकृतः ।
यश्चाशेषतपःप्रभावदिनकृत्युद्यत्तमोवल्लरी
श्रस्यत्कामकषायकौशिकभरत्रैलोक्यकीर्तिं नुमः ॥
दानं यस्य मनोरथावधि यशो निःशेषलोकावधि-
मैत्री सत्त्वकथावधिः परिणतिस्तत्त्वावबोधावधिः ।
भक्तिः श्रीगुरुपादपंकजनिजाहंकारसारावधि-
र्नेमिर्जोमणनंदनो विजयतामानल्पकल्पावधिः ॥

इतिश्रींद्रवामदेवविरचिते पुरवाटवंशविशेषकश्रीनेमिदेवस्य यशःप्रकाशके पंच-संग्रहदीपके

पत्र १०४

तस्मादजायत जिनेन्द्रपदाब्जभृंगः श्रीजोमणस्तदनुजो भुवि लाहिदेवः ।
........कलाविलासैः राज्ञां मनांसि महतामपि रंजितानि ॥ छ ॥ २२० ॥ छ ॥

तत्र श्री...... जोमणस्य दुहिता जाता गुणाग्रेसरा
धर्मारामतरोः प्रवर्द्धनसुधाकुल्यैकपुण्योदका ।
श्रीसर्वज्ञपदारविंदनिरता सद्दानचिंतामणि-
श्चारित्रव्रतदेवतासु विदिता श्रीवाइदे...... ॥ २२१ ॥

ताभ्यामिंदुमुखो विचारवसतिः सौजन्यपुण्याकृति-
र्नानाशास्त्रविनोदमेदुरमना.......... ।
............कर्णरसायनैर्गुणगणैर्विस्मापितक्ष्मातलः
क्षोणीपीठसुरद्रुमः स्थिरयशाः श्रीनेमि........ ॥ २२२ ॥

प्रातः श्रीजिनपूजनेन विधिना मध्याह्नकालेऽप्ययं
दाननाद्भुतकीर्त्तिनो मुनिजनाशीर्वाद........ ।
...................................स्य स्वयं
नित्यं पुण्यदिनः स नंदतु चिरं श्रीनेमिदेवः सुधीः ॥ २२३ ॥ छ ॥

तेना....................................... ।
.......................णेनाहं वशीकृतमनोरथः ॥ छ ॥ २२४ ॥

ततो व्यावृत्य निःशेषव्यापा..................... ।
.... ॥ २२५ ॥

ततस्तस्य प्रसादेन वीतचिंताभरादहम् ।
जिनेश्वरपदद्वंद्वस्मरणक्षालिता............ ॥ २२६ ॥

....दरो
नानाशास्त्रविचारकोविदमतिः श्रीवामदेवः कृती ।
चक्रे शास्त्रमिदं विनष्ट...............
.......................द्विक्ष्मातलम् ॥ २२७ ॥

यो नित्यं पठति स्वयं गुरुजनाद् ज्ञात्वा प्रसन्नः पाठयेत्
यो...................................

No. 140 Vītarāgastotra वीतरागस्तोत्र

Folios – 70 to 99
Language – Sanskrit
Author – Hemacandrācārya
Size – 12 × 1·7 inches
Condition – Good
Age of MS. – c. End of 13th cent V. S.

*

No. 141 (1) Bṛhatsaṅgrahaṇīprakaraṇa
(१) बृहत्संग्रहणीप्रकरण

Folios – 65
Language – Prakrit
Author – Jinabhadragaṇi Kṣamāśramaṇa
Age of MS. – c. First half of 13th cent. V. S.
Extent – Gāthās 271
Size – 9 × 1·5 inches
Condition – Good

(2) Jambūdvīpakṣetrasamāsaprakaraṇa
(२) जंबूद्वीपक्षेत्रसमासप्रकरण

Folios – 65 to 77
Language – Prakrit
Age of MS. – c. First half of 13th cent. V. S.
Extent – Gāthās 88
Size – 9 × 1·5 inches
Condition – Good

*

No. 142 Jīvasamāsaprakaraṇa with Commentary
जीवसमासप्रकरण सटीक

Folios – 194
Language – Prakrit & Sanskrit
Commentator – Maladhārī Hemacandrasūri
Age of MS. – V. S. 1165
Extent – Granthas 6627
Size – 26 × 2 inches
Condition – Good
General Remarks – Folio 112 missing. Folio 194 contains two nice decorative pictures.

आदिः—

॥ ॐ नमो वीतरागाय ॥

यः स्फारकेवलकैर्जगतां निहत्य हार्दं तमः प्रकटिताखिलतत्त्ववस्तुः ।
नित्योदितो सुरवरैः स्तुतपादपद्मोऽपूर्वो रविर्विजयते स जिनेन्द्रवीरः ॥ १ ॥
प्रणमामि चरणयुगलं तेषां श्रीगौतमादिसूरीणाम् ।
यैर्जलदैरिव वृष्टं सूत्रजलैर्भव्यवसुधासु ॥ २ ॥
कामधेनुरिवाशेषकामितार्थप्रसाधनी ।
या स्तुता सर्वगीर्वाणैः स्तौमि तां श्रुतदेवताम् ॥ ३ ॥

विशेषतश्च नत्वाऽऽत्मगुरूणां पद्पंकजम् ।
वृत्तिं जीवसमासस्य वीतविघ्नः प्रवच्म्यहम् ॥ ४ ॥

तत्र चायुर्बलमेधादिभिरपचीयमानान् साम्प्रतकालीनजंतून् समवलोक्य तदनुग्रहार्थमन्यत्र विस्तराभिहितान् जीवगुणस्थानादिकान् भावान् संक्षिप्य प्रतिपादयितुं **जीवसमास**संज्ञितं प्रकरणं चिकीर्षुराचार्यो निःशेषप्रत्यूहोपशमाय मङ्गलगर्भां प्रेक्षावत्प्रवृत्त्यर्थं सम्बंधाभिधेयप्रयोजनगर्भां च गाथामाह—

दस चोद्दस य जिणवरे चोद्दसगुणजाणए नमंसित्ता ।
चोद्दसजीवसमासे समासओऽणुक्कमिस्सामि ॥

अंतः—

एकैकस्यापि प्रदेशस्यानुगतव्यावृत्तानन्तपर्यायात्मकत्वादिति गाथार्थः ॥ छ ॥ २८७॥ तदेवमन्या अपि प्रक्षेपगाथाः सिद्धान्तानुसारेण व्याख्येयाः। जीवसमासवृत्तिः समाप्ता ॥ * ॥

यद् वृत्ताविह वस्तु प्रायस्तत् समयसागराल्लिखितम् ।
मन्मतिदोषाद् दुष्टं तथापि शोध्यं बुधैः सर्वम् ॥
जीवसमासस्यैतां वृत्तिं कृत्वा मयाऽऽपि यत् पुण्यम् ।
जीवादितत्त्वमधिगम्य तेन शिवमाप्नुवन्तु जनाः ॥

श्रीप्रश्नवाहनकुलाम्बुनिधिप्रसूतः क्षोणीतलप्रथितकीर्तिरुदीर्णशाखः ।
विश्वप्रसाधितविकल्पितवस्तुरुच्चैः० ॥ १ ॥ इत्यादि [क्रमांक ३९]
श्रीहेमचन्द्रसूरिभिरियमनुरचिता प्रकृतवृत्तिः ॥ १० ॥

प्रत्यक्षरगणनया चात्र सर्वग्रन्थाग्रमनुष्टुभां षट् सहस्राणि षट् शताधिकानि सप्ताविंशतिः श्लोकाः ॥ ॥ अंकतोऽपि ६६२७ ॥ छ ॥ संवत् ११६५ चैत्र शुदि ५ सोमेऽद्येह श्रीमदणहिलपाटके समस्तराजावलीविराजितमहाराजाधिराजपरमेश्वरश्रीमज्जयसिंहदेवकल्याणविजयराज्ये एवं काले प्रवर्त्तमाने यमनियमस्वाध्यायध्यानानुष्ठानरतपरमनैष्ठिक पण्डित श्वेताम्बराचार्य भट्टारक श्रीहेमचन्द्राचार्येण पुस्तिका लि. लि. ॥

*

No. 143 (1) Tattvārthādhigamaśāstravṛtti

(1) तत्त्वार्थाधिगमशास्त्रवृत्ति

Folios – 340
Language – Sanskrit
Author – Siddhasenasūri
Age of MS. – V. S. 1445

Extent – Granthas 18282
Size – 33·7 × 2·2 inches
Condition – Fair

आदिः—

वीरं प्रणम्य सर्वज्ञं **तत्त्वार्थस्य** विधीयते ।
टीका संक्षेपतः स्पष्टा मंदबुद्धिविबोधिनी ॥ १ ॥

सम्यगर्हत्प्रवचनमधिगम्य कालसंहननश्रद्धावपुरादेः परिहाणिमवलोक्य सत्त्वानुकंपया समासतो मोक्षमार्गमुपदेष्टुकाम आचार्य इदमाह—

सम्यदर्शनशुद्धं यो ज्ञानं विरतिमेव चाप्नोति ।........
दर्शनशुद्धमिति कतरो विग्रह आस्थीयते ॥

अंतः—

तत्रोक्तं सोऽव्याबाधसुलक्षणमनंतमनुपमं परमार्थं मोक्षमचिरेण प्राप्स्यतीति ॥ छ ॥

आसीद्**दिन्नगणी क्षमाश्रमण**तां प्राप क्रमेणैव यो
विद्वत्सु प्रतिभागुणेन जयिना प्रख्यातकीर्तिर्भृशम् ।
वोढा शीलभरस्य सच्छ्रुतनिधिर्मोक्षार्थिनामग्रणीः
जज्वालामलमुच्चकैर्निजतपस्तेजोभिरव्याहतम् ॥ १ ॥
यत्र स्थितं प्रवचनं पुस्तकनिरपेक्षमक्षतं विमलम् ।
शिष्यगणसंप्रदेयं जिनेन्द्रवक्त्राद्विनिष्क्रान्तम् ॥ २ ॥
तस्याऽभूत् परवादिनिर्जयपटुः सैंहीं दधच्छूरतां
नाम्ना व्यज्यत **सिंहसूर** इति च ज्ञाताखिलार्थागमः ।
शिष्यः शिष्टजनप्रियः प्रियहितव्याहारचेष्टाश्रयाद्
भव्यानां शरणं भवौघपतनक्लेशार्दितानां भुवि ॥ ३ ॥
निर्द्धूततमःसंहतिरखंडमंडलशशांकसच्छाया ।
अद्यापि यस्य कीर्त्तिर्भ्रमति दिगंतानविश्रांता ॥ ४ ॥
शिष्यस्तस्य बभूव राजकशिरोरत्नप्रभाजालक-
व्यासंगच्छुरितस्फुरन्नखमणिप्रोद्भासिपादद्वयः ।
भास्वामीति विजित्य नाम जगृहे यस्तेजसां संपदा
भास्वंतं भवनिर्जयोद्यतमतिर्विद्वज्जनाग्रेसरः ॥ ५ ॥
क्षमया युक्तोऽतुलया समस्तशास्त्रार्थविन्महाश्रमणः ।
गच्छाधिपगुणयोगाद्गणाधिपत्यं चकारार्घ्यम् ॥ ६ ॥
तत्पादरजोऽवयवः स्वल्पागमशेमुषीकबहुजाड्यः ।
तत्त्वार्थशास्त्रटीकामिमां व्यधात् सिद्धसेनगणिः ॥ ७ ॥

अष्टादश सहस्राणि द्वे शते च तथाऽपरे ।
अशीतिरधिका द्वाभ्यां टीकाया [ग्रन्थ]संग्रहः ॥ ८ ॥
ग्रंथाग्रं १८२८२ ॥ **तत्त्वार्थटीका समाप्ता** ॥ छ ॥

(2) Tattvārthādhigamaśāstra
(२) **तत्त्वार्थाधिगमशास्त्र—मूल**

Folios – 340 to 343
Language – Sanskrit
Author – Umāswāti Vācaka
Age of MS. – V.S. 1445
Size – 33·7 × 2·2 inches
Condition – Fair

आदिः—

सिद्धिः ॥ ॐ नमो वीतरागाय ॥
मोक्षमार्गस्य नेतारं भेत्तारं कर्मभूभृताम् ।
ज्ञातारं विश्वतत्त्वानां वन्दे तद्गुणलब्धये ॥ १
सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः १ ।

अंतः—

क्षेत्रकालगतिलिंगतीर्थचारित्रप्रत्येकबुद्धबुद्धबोधितज्ञानावगाहनान्तरसंख्याल्पबहुत्वतः साध्याः ॥ इति **तत्त्वार्थाधिगमे मोक्षशास्त्रे दशमोऽध्यायः** ॥ छ ॥

(3) Tattvārthādhigamaśāstra with Svopajña Bhāṣya
(३) **तत्त्वार्थाधिगमशास्त्र – स्वोपज्ञभाष्य सहित**

Folios – 343 to 383
Language – Sanskrit
Author & Commentator – Umāsvātivācaka
Age of MS. – V.S. 1445
Size – 33·7 × 2·2 inches
Condition – Fair

आदिः—

॥ ॐ नमः सिद्धेभ्यः ॥
सम्यग्दर्शनशुद्धं यो ज्ञानं विरतिमेवं चाप्नोति ।
दुःखनिमित्तमपीदं तेन सुलब्धं भवति जन्म ॥

अन्तः —

प्राप्स्यत्यचिरेण परमार्थम् ॥ छ ॥ **तत्त्वार्थाधिगमे जिनप्रवचनसंग्रहे भाष्यतः दशमोऽध्यायः समाप्तः** ॥ छ ॥ छ ॥ संवत् १४४५ वर्षे अश्विन सुदि ४ गुरौ अद्येह **श्रीस्तंभती......**

*

No. 144 Karmaprakṛtiprakaraṇa with Commentary
कर्मप्रकृतिप्रकरण सटीक

Folios – 276
Language – Prakrit & Sanskrit
Author – Śivaśarmasūri
Commentator – Ācārya Malayagiri

Extent – Gāthās 475
Size – 26·7 × 1·5 inches
Age of MS. – V.S. 1451
Condition – Good

आदिः—

॥ ॐ नमो वीतरागाय ॥

प्रणम्य कर्मद्रुमचक्रनेमिं नमत्सुराधीश**मरिष्टनेमिम्** ।
कर्मप्रकृत्याः कियतां पदानां सुखावबोधाय करोमि टीकाम् ॥ १
अयं गुण**श्चूर्णिकृतः** समग्रो यदस्मदादिर्वदतीह किंचित् ।
उपाधिसम्पर्कवशाद्विशेषो लोकेऽपि दृष्टः स्फटिकोपमस्य ॥ २

इह शिष्टाः **क्वचिदिष्टे** वस्तुनि प्रवर्त्तमानाः सन्त इष्टदेवतानमस्कारपुरस्सरमेव प्रवर्त्तन्ते ।

अंतः—

कर्मप्रपंचं जगतोऽनुबन्धक्लेशावहं वीक्ष्य कृपापरीतः ।
क्षयाय तस्योपदिदेश रत्नत्रयं स जीयाज्जिन**वर्द्धमानः** ॥ १
निरस्तकुमतध्वान्तं सत्पदार्थप्रकाशकम् ।
नित्योदयं नमस्कुर्मो जैनं सिद्धान्तभास्करम् ॥ २
पूर्वान्तर्गत**कर्मप्रकृति**प्राभृतसमुद्धृता येन ।
कर्मप्रकृतिरियमतः श्रुतकेवलिगम्यभावार्था ॥ ३
ततः क्वैषा विषमार्थयुक्ता क्व चाल्पशास्त्रार्थकृतश्रमोऽहम् ।
तथापि सम्यग्गुरुसम्प्रदायात् किंचित् स्फुटार्था विवृता मयैषा ॥ ४
कर्मप्रकृतिनिधानं बह्वर्थं येन मादृशां योग्यम् ।
चक्रे परोपकृतये श्री**चूर्णिकृते** नमस्तस्मै ॥ ५
एनामतिगम्भीरां **कर्मप्रकृतिं** विवृण्वता कुशलम् ।
यदवापि **मलयगिरिणा** सिद्धिं तेनाश्नुतां लोकः ॥ ६
अर्हन्तो मंगलं मे स्युः सिद्धाश्च मम मंगलम् ।
मंगलं साधवः सम्यग् जैनो धर्मश्च मंगलम् ॥ ७ ॥ इति ॥ छ ॥

संवत् १४५१ वर्षे फागुण वदि १२ बुधे अद्येह **स्तम्भतीर्थे कर्मप्रकृति**-वृत्तिपुस्तिका लिखितमस्ति ॥ छ ॥ शुभं भवतु ॥

*

No. 145 Pañcasaṅgraha with Commentary–Part I

पंचसंग्रह सटीक—प्रथमखंड

Folios – 269
Extent – Granthas 4631
Language - Prakrit & Sanskrit
Size – 16 × 2 inches
Author – Candrarṣi Mahattara
Condition – Fair
Commentator – Ācārya Malayagiri
Age of MS. – c. End of 13th cent. V.S.
General Remarks – A broken leaf contains the following words:

"श्रीमलयगिरिकृत पंचसंग्रहटीका पु. १ । ग्रंथाग्रं ४६३१ ।
पत्र २७०–षटयड सा० आसधररत्नसिंहयो: ॥"

*

No. 146 Śatakapañcamakarmagranthacūrṇi

शतकपंचमकर्मग्रंथचूर्णि

Folios – 120
Size – 14 × 2·2 inches
Language – Prakrit
Condition – Good
Author – Candrarṣi Mahattara
Age of MS. – c. Latter half of 12th cent. VS.

आदि:—

सिद्धो निद्धुयकंमो सद्धम्मपणायगो तिजगनाहो ।
........................द्धसक्कारा ।
सव्वजगमज्झयारे सुयकेवलिणो जयंति सया ॥
जिणवरमुहसंभूया गण........................ ।
........................सुयदेवी सया जयउ ॥

अन्त:—

....................ष्टा येषां प्रसादाद्वरधर्मलाभ: ।
सज्ज्ञानसम्पद्विमला च दृष्टि: लोके महत्त्वं सुगतिस्सका.... ॥
........॥ छ ॥ * ॥ कृतिराचार्यश्रीचंद्रमहत्तरशितांबरस्य शतकस्य ग्रंथस्य ॥
प्रशस्तचू........वदि ६ शनौ पुस्तिका लिखितेति ॥ छ ॥

*

No. 147 Āgamikavastuvicārasāraprakaraṇa with Commentary–Fourth Ancient Karmagrantha

आगमिकवस्तुविचारसारप्रकरण—चतुर्थ प्राचीन कर्मग्रंथ—सटीक

Folios – 69
Extent – Granthas 850
Language – Prakrit & Sanskrit
Size – 14 × 2 inches
Author – Jinavallabhagaṇi
Date of Composition – V.S. 1172
Commentator – Haribhadrasūri of Bṛhadgaccha
Age of MS. – V. S. 1216

आदिः—

॥ ॐ ॥

नत्वा जिनं विधास्ये विवृतिं **जिनवल्लभ**प्रणीतस्य ।
आगमिकवस्तुविस्तरविचारसारप्रकरणस्य ॥ १ ॥

इह **जिनवल्लभ**गणिनामा सूत्रकारो गणधरदेवादिनिबद्धातिगंभरिशास्त्रार्थावगाहनाऽसमर्थानां विशिष्टसंहननायुर्मेधादिविकलानां कलिकालोत्पन्नमानवानामनुग्रहाय सूक्ष्मार्थसार्थप्रकाशनार्थं प्रस्तुतप्रकरणं चिकीर्षुर्मंगलादिप्रतिपादकमिदमादौ गाथाद्वितयमाह ।

अन्तः—

इत्यागमिकवस्तुविचारसारप्रकरणवृत्तिः समाप्ता ॥ छ ॥ * ॥

प्रायोऽन्यशास्त्रदृष्टः सर्वोऽप्यर्थो मयाऽत्र संरचितः ।
न पुनः स्वमनीषिकया तथापि यत् किंचिदिह वितथम् ॥ १ ॥

सूत्रमतिलंघ्य लिखितं तच्छोध्यं मय्यनुग्रहं कृत्वा ।
परकीयदोषगुणयोस्त्यागोपादानविधिकुशलैः ॥ २ ॥

छद्मस्थस्य हि बुद्धिः स्खलति न कस्येह कर्मवशगस्य ।
सद्बुद्धिविरहितानां विशेषतो मद्विधासुमताम् ॥ ३ ॥

कृत्वा यद् वृत्तिमिमां पुण्यं समुपार्जितं मया तेन ।
मुक्तिमचिरेण लभतां क्षपितरजाः सर्वभव्यजनः ॥ ४ ॥

मध्यस्थभावादचलप्रतिष्ठः सुवर्णरूपः सुमनोनिवासः ।
अस्मिन् महामेरुरिवास्ति लोके श्रीमान् **बृहद्गच्छ** इति प्रसिद्धः ॥ ५ ॥

तस्मिन्नभूदायतबाहुशाखः कल्पद्रुमाभः प्रभु**मानदेवः** ।
यदीयवाचो विबुधैः सुबोधाः कर्णे कृता नूतनमंजरीव ॥ ६ ॥

तस्मादुपाध्याय इहाऽजनिष्ट श्रीमान् मनस्वी **जिनदेव**नामा ।
गुरुक्रमाराधयताल्पबुद्धिस्तस्यास्ति शिष्यो **हरिभद्रसूरिः** ॥ ७ ॥

अणहिल्लपाटकपुरे श्रीमज्जयसिंहदेवनृपराज्ये ।
आशापूरवसत्यां वृत्तिस्तेनेयमारचिता ॥ ८ ॥

एकैकाक्षरगणनादस्या वृत्तेरनुष्टुभां मानम् ।
अष्टौ शतानि जातं पंचाशत्समधिकानीति ॥ ९ ॥

वर्षशतैकादशके द्वासप्तत्याधिके नभोमासे ।
सितपंचम्यां सूर्ये समर्थिता वृत्तिकेयमिति ॥ छ ॥

इति षडशीतिप्रकरणवृत्तिः समाप्ता ॥ छ ॥ ॥ छ ॥ मंगलं महाश्रीः ॥ छ ॥
संवत् १२१६ वर्षे ज्येष्ठ शुदि ६ शुक्रे ॥ छ ॥

*

No 148 Six Karmagranthas with Commentary
कर्मग्रन्थषट्क सटीक

Folios – 271
Language – Prakrit & Sanskrit
Author & Comm. of first 5 – Devendrasūri
Commentator of the 6th – Ācārya Malayagiri

Extent – Granthas 14000
Size – 33·2 × 1·7 inches
Condition – Good
Age of MS. – V. S. 1447

आदिः—

॥ ॐ नमः प्रवचनाय ॥

दिनेशवद् ध्यानवरप्रतापैरनंतकालप्रचितं समंतात् ।
योऽशोषयत्कर्मविपाकपंकं देवो मुदे वोऽस्तु स **वर्द्धमानः** ॥ १ ॥

ज्ञानादिगुणगुरूणां धर्मगुरूणां प्रणम्य पदकमलम् ।
कर्मविपाके विवृतिं स्मृतिबीजविवृद्धये विदधे ॥ २ ॥

तत्रादावेवाभीष्टदेवतास्तुत्यादिप्रतिपादिकामिमां गाथामाह ॥ छ ॥

सिरिवीरजिणं वंदिय **कम्मविवागं** समासओ वुच्छं ।
कीरइ जिएण हेऊहिं जेण तो भन्नए कम्मं ॥ १ ॥

अन्तः—

निरुपममनंतमनघं शिवपदमधिरूढमपगतकलंकं ।
दर्शितशिवपुरमार्गं **वीरजिनं** नमत परमशिवं ॥ १ ॥

यस्योपांतेऽपि संप्राप्ते प्राप्यन्ते संपदोऽनघः ।
नमस्तस्मै जिनेश**श्रीवीरसिद्धांतसिंधवे** ॥ २ ॥

येरेषा विषमार्था **सप्ततिका** सुस्फुटा कृता सम्यक् ।
अनुपकृतपरोपकृतश्चूर्णिकृतस्तान् नमस्कुर्वे ॥ ३ ॥
प्रकरणमेतद्विषमं **सप्ततिकाख्यं** विवृण्वता कुशलम् ।
यदवापि **मलयगिरिणा** सिद्धिं तेनाश्नुतां लोकः ॥ ४ ॥
अर्हंतो मंगलं सिद्धा मंगलं संयतानहम् ।
अशिश्रियं जिनाख्यातं धर्मं परममंगलम् ॥ ५ ॥

इति श्री**मलयगिरिविरचिता सप्ततिकाटीका समाप्ता** । ग्रंथाग्रं ३८८० ॥छ॥

ॐ ॥ **ऊकेशवंश**भूषण सा० **पद्म**सुत सा० **वीजड**भार्या **वीकमदे** तत्सुता श्रा० **सारू**नाम्नी सा० **आमसीह**सुत सा० **धर्मसीह**भार्या सर्वदा नानाविधपुण्यकृत्य-परायणा श्रीम**त्तपागच्छ**मंडनसुविहितचक्रचूडामणिभट्टारकश्री**देवसुंदरसूरी**णामुपदेशेन स्व-श्रेयसे **नव्यकर्मग्रन्थवृत्तिपुस्तकं** श्रीविक्रमनृपसंवत् १४४७ वर्षे लेखयामास । आचंद्रार्कं पुस्तकोऽयं बुधैर्वाच्यमानो नंदतात् ॥ छ ॥ कर्मग्रंथ १४००० टीका ॥

*

No. 149 : (1) Karmastava Karmagrantha Ṭīkā
Second Ancient Karmagrantha-Commentary

(१) कर्मस्तव कर्मग्रन्थ टीका-प्राचीन द्वितीय कर्मग्रन्थ टीका

Folios – 94 | Extent – Granthas 1090
Language – Sanskrit | Size – 13·2 × 1·5 inches
Author – Govindagaṇi | Condition – Good
Age of MS. – c. First half of 15th cent. V. S.

आदिः—

॥ ॐ नमः सर्वज्ञाय ॥

कर्मबंधोदयोदीर्यासत्तावैचित्र्यवेदिनम् ।
कर्मस्तवस्य टीकेयं नत्वा वीरं विरच्यते ॥ १ ॥

नमिऊणेत्यादि । पूर्वार्द्धेन मंगलार्थमिष्टदेवतानमस्कारमाह । मंगलमविघ्नेन प्रकरणसमाप्त्यर्थं । पश्चार्द्धेन प्रयोजनादि त्रयमिति गाथासमुदायार्थः ।

अन्तः—

स्मृत्यनुसारेण मया यद्वदितमिहोनमधिकमागमतः ।
तत् क्षंतव्यं श्रुतशुद्धबुद्धिभिः शोधनीयं च ॥ १ ॥

इति श्वेतपटाचार्यगोविंदगणिना कृता ।
कर्मस्तवस्य टीकेयं देवनागगुरोर्गिरा ॥ २ ॥ छ ॥
समाप्ता चेयं कर्मस्तवटीका ॥ छ ॥

अनुष्टुप् छन्दसां प्रायः संकलय्याऽनुवर्णितम् ।
सहस्रमेकं श्लोकानां नवत्युत्तरमेव तु ॥

शिवमस्तु सर्वजगतः लेखकपाठकवाचकानां ॥ छ ॥ मंगलं महाश्रीः ॥ छ ॥

(2) Karmavipāka Karmagrantha with Vṛtti–Ancient

(२) कर्मविपाक कर्मग्रन्थ वृत्ति सह–प्राचीन

Folios – 95 to 163
Language – Prakrit & Sanskrit
Author – Gargarṣi
Commentator – Paramānandasūri
Age of MS. – c. first half of 15th cent. V.S.

Extent – 922 Vṛtti granthas
Size – 13.2 × 1.5 inches
Condition – Good

आदिः—

॥ ॐ नमः सर्वविदे ॥

निःशेषकर्मोदयमेघजालमुक्तो दिनाधीश इवोग्रतेजाः ।
प्रदर्शिताशेषपदार्थसार्थो मुदेऽस्तु नः श्रीजिनवर्द्धमानः ॥ १ ॥

अन्तः—

श्रीभद्रेश्वरसूरिशिष्यतिलकश्रीशांतिसूरिप्रभोः
श्रीमंतोऽभयदेवसूरिगुरवः सिंहासनोत्तंसकाः ।
तत्पादांबुजषट्पदेन परमानंदेन सत्प्रीतये
चक्रे कर्मविपाकवृत्तिमिषतः श्रोत्रैकलेह्यं मधु ॥ १ ॥

यन्नागमानुगामि स्यान्न वा संगतिमंगति ।
इह तत्साधुभिः शोध्यमनभ्यर्थितवत्सलैः ॥ २ ॥

प्रत्यक्षरं निरूप्यास्य ग्रंथाग्रं परिनिश्चितम् ।
अनुष्टुभां नवशती द्वाविंशत्यधिका भवेत् ॥ ३ ॥

अंकतो ९२२ कर्मविपाकवृत्तिः समाप्तेति ॥ छ ॥

*

No. 150 : Bṛhatsaṅgrahaṇīprakaraṇa with Commentary

बृहत्संग्रहणीप्रकरण सटीक

Folios – 2 to 245
Size – 13 × 2 inches.

Language – Prakrit & Sanskrit
Author – Jinabhadragaṇi Kṣamāśramaṇa
Commentator – Ācārya Malayagiri
Condition – Good
Age of MS. – V.S. 1287

अन्तः—

॥ इति श्रीमलयगिरिविरचिता संग्रहणीटीका समाप्ता ॥

अर्हन्तः शरणं सिद्धाः शरणं साधवो मम ।

शरणं शरणं धर्मस्तान् शरणमशिश्रियम् ॥ छ ॥

मंगलं महाश्रीः ॥ छ ॥ संवत् १२८७ वर्षे वैशाष शुदि ३ गुरौ इहैव **वीजापुरीयश्रावकपौषधशालायां** पूज्यश्रीदेवेंद्रसूरि श्रीविजयचन्द्रसूरि उपाध्यायश्री-**देवभद्रगणिसद्गुरूणां** धर्मोपदेशतः सा. रतनपाल श्रे० **वील्हण** ठ० **आसपाल** सा० **लाहड** प्रभृतीनां **संघयणिवृत्ति** पुस्तिका लिखापिताः ॥ छ ॥

*

No. 151: Śrīcandrīya Saṅgrahaṇīprakaraṇa with Commentary

श्रीचन्द्रीय संग्रहणीप्रकरण सटीक

Folios – 360
Language – Prakrit & Sanskrit
Author – Śrīcandrasūri
Commentator – Devabhadrasūri
Age of MS. – c. latter half of 13th cent. V.S.
Extent – Granthas 3500
Size – 17·5 × 1·2 inches
Condition – Good

आदिः—

॥ ॐ नमः सर्वज्ञाय ॥

अत्यद्भुतं योगिभिरप्यगम्यं विधूतनिःशेषतमोवितानम् ।
अचिंत्यमाहात्म्यमजं निरंजनं ज्योतिर्जयत्येकमनंतमव्ययम् ॥ १ ॥

यस्यामृतैर्वचोभिर्जीवत्यद्यापि भव्यलोकोऽयम् ।
स जयत्यागमजलधि**र्जिनभद्रगणिः** क्षमाश्रमणः ॥ २ ॥

प्रसन्नगंभीरपदाहितक्रमा मिताक्षरा वर्जितपौनरुक्त्या ।
यैर्निर्मिता **संग्रहणी**यमद्भुता नमो नमस्तत्पदपंकजेभ्यः ॥ ३ ॥

इह तावच्छास्त्रादौ संक्षिप्तरुचिना प्रायः शिष्टसमयानुवृत्तये विघ्नोपशांतये च परममंगलालयोऽभीष्टदेवतास्तवः ।

अन्तः—

तदेवं व्याख्याता चतुर्विंशतिद्वारात्मिका गाथाद्वयप्रमाणा संक्षिप्ततरा **संग्रहणि-सद्व्याख्यानाच्च** **श्रीहर्षपुरीयगच्छालंकारमलधारिश्रीमदभयदेवसूरिपट्टरत्नश्रीहेमचंद्रसूरि-**शिष्य**श्रीचंद्रसूरि**चरणांबुजचंचरीकेण श्री**मुनिचंद्र**सूरिभ्यो लब्धप्रतिष्ठेन श्री**देवभद्र**सूरिणा विरचिता स्वगुरुप्रणीत**संग्रहण्या वृत्तिः** समर्थिता ॥ छ ॥

अंगान्युपांगानि तथा पराणि विलोक्य शास्त्राणि गुरूपदेशात् ।
विनिर्मिता वृत्तिरियं तथापि शोध्यं यदि स्याद्विबुधैर्विशोध्यम् ॥ १ ॥

निजगुरुपदभक्तेः कुर्वतो वृत्तिमेनां मम समजनि पुण्यं यत्ततो भव्यलोकः ।
जिनपतिमतपोतात्तीर्णसंसारसिंधुर्व्रजतु शिवमनंतज्ञानदृग्वीर्यसौख्यम् ॥ २ ॥

प्रत्यक्षरगणनातो ग्रंथमानं विनिश्चितम् ।
पंचत्रिंशच्छतान्यत्र श्लोकानां सर्वसंख्यया ॥ ३ ॥ छ ॥

इति **श्रीलघुसंग्रहणिवृत्तिः** समाप्ता ॥ छ ॥

यादृशं पुस्तके दृष्टं तादृशं लिखितं मया ।
यदि शुद्धमशुद्धं वा मम दोषो न दीयते ॥ १ ॥

अक्षरमात्रपदस्वरहीनं व्यंजनसंधिविवर्जितरेफम् ।
साधुभिरेव मम क्षमितव्यं कोऽत्र न मुह्यति शास्त्रसमुद्रे ॥ २ ॥

भग्नपृष्ठिकटिग्रीवा स्तब्धदृष्टिरधोमुखम् ।
कष्टेन लिखितं शास्त्रं यत्नेन प्रतिपालयेत् ॥ ३ ॥ छ ॥ शुभं भवतु ॥ छ ॥

*

No. 152 : Caityavandanabhāṣya with Saṅghācāravṛtti
चैत्यवन्दनभाष्य संघाचारवृत्ति सहित

Folios – 272
Language – Prakrit & Sanskrit
Author – Devendrasūri
Commentator – Dharmaghoṣasūri
Age of MS. – c. Latter half of 13th cent. V.S.

Size – 33 × 2·5 inches
Condition – Good

आदिः—

॥ ॐ नमः प्रवचनाय ॥

देवेन्द्रवृंदस्तुतपादपद्मः स्वर्भूर्भुवःश्रीवरकेलिसद्म ।
संदेहसंदोहरजःसमीरः स वः शिवायाऽस्तु जिनेन्द्रवीरः ॥ १ ॥

चैत्यमुनिवंदनप्रभृतिभाष्यविवृतेर्यथाश्रुतं किंचित् ।
संघस्याचारविधिं वक्ष्ये स्वपरोपकाराय ॥ २ ॥

इह हि दुरंतानंतचतुरंतासारविसारिसंसारापारगभीरपारावारे निमज्जता भव्यजंतुना जिनप्रवचनप्रतीतचोल्लकादिदशनिदर्शनदुःप्रापां कथमपि प्रशस्तसमस्तमनुजजन्मादिसामग्री-मवाप्य भवजलधिसमुत्तरणप्रवणप्रवहणसधर्मसद्धर्मविधाने प्रयत्नो विधेयः ॥

अंतः—

अंगोपांग-प्रकीर्णोल्लसद्**ऋषिभणित**-च्छेद-सन्मूलकर्मग्रंथेत्यादिस्वरूपश्रुतजलधिविधि-प्रावगाहप्रवीणान् ।

श्रीम**द्देवेन्द्रसूरे**र्विविधविधियुत.......
रार्थप्रथितकथपथः शेषविध्यादिवर्ण्णी ॥ १ ॥

इति श्रीसंघस्य प्रतिदिनमवश्यं कृतिविधौ सुधर्मानुष्ठाने प्रकटमधिकारः प्रथमकः ।
सदाऽर्हच्चैत्यानां विहितविधिवद्वंदनवरः श्रुतादाम्नायाच्च प्रकृतविवृतिः पारमगमत् ॥ २ ॥

इति श्री**देवेन्द्रसूरि**शिष्यमहोपाध्यायश्री**धर्मकीर्त्ति**कीर्त्तिते प्रतिदिनावश्यकृत्य-श्री**संघाचारविधि**नाम्नि **चैत्यवंदनादिविवरणे** चैत्यवंदनाविधानाभिधानप्रथमाधिकारे चैत्य-वंदनाविशेषविधिस्वरूपादिवर्णनो नाम चतुर्थः प्रस्तावः ॥ छ ॥

एवं समर्थितश्चैत्यवंदनाविधिनामा प्रथमोऽधिकारः ॥ छ ॥

जयति श्रीजिनशासनमुदितश्रुत**धर्मघोष**सुविशुद्धि ।
यत्र सदाऽपि हि साधुः प्रवरप्रल्हादनपुरस्तात् ॥ १ ॥

श्री**धर्मकीर्त्ति**कर्त्ता गौरव्योऽन्योऽपि **धर्मघोष** इव ।
श्रुतदुग्धाद्युपलब्धिः किमु सच्चरणाध्वनीनस्तु ॥ २ ॥

सर्वज्ञाख्यः पिता यस्य गुरुर्गीष्पतिनामतः ।
निरवद्यसर्व**विद्यानंद**यो विश्वनंदये ॥ ३ ॥

शुद्धक्रियादिसंश्लेषशालिनस्तस्य काव्यराजस्य ।
लघुबंधोर्वृत्तिरियं स्वपरोपकृतौ कृतार्थाऽस्तु ॥ ४ ॥

अर्हन्तो मम मंगलं विदधतां **देवेन्द्र**वंद्यक्रमा
विद्यानंदमयास्तु मंगलमलं कुर्वन्तु सिद्धा मयि ।

मह्यं मंगलमस्तु साधुनिकरः सद्धर्मकीर्त्तौ स्थितो
मंगल्यं श्रुतधर्मघोषणपरं धर्मे सुदृग्भिः श्रये ॥ ५ ॥ छ ॥

शुभं भवतु लेखकपाठकयोः ॥ मंगलं महाश्रीः ॥ छ ॥

*

No. 153: Siddhajayantīprakaraṇa with Commentary-Jayantīcaritra

सिद्धजयन्तीप्रकरण—सटीक—जयन्तीचरित्र

Folios – 172
Language – Prakrit & Sanskrit
Author – Mānatuṅgasūri
Commentator – Malayaprabhasūri

Size – 31 × 2.2 inches
Condition – Good
Date of Composition – 1260 V.S.
Age of MS. – V.S. 1261

आदिः—

॥ ॐ नमो वीरजिनाय ॥

सर्वाशाः परिपूर्णतां वसुचयैः संप्रापयन्नन्वहं
जीवाजीवविचारकैरववनप्रोद्बोधचन्द्रोदयः ।
धर्माधर्मविवेकदुग्धजलधेर्वृद्धिं दधानोऽधिकां
स श्रीनाभिनृपांगजो जिनपतिस्तादिष्टसंसिद्धये ॥ १ ॥

यः कल्याणगिरीन्द्रसुंदरवपुर्गोत्राधिकामुन्नतिं
बिभ्राणः शुशुभे ससम्मदसुरैः संसेव्यपादोऽन्वहम् ।
धर्माख्यानविधाननंदनवने प्रोत्फुल्लपुष्पश्रियो
रेजुर्यद्दशनांशवः स भगवान् वीरो जिनः पातु वः ॥ २ ॥

रागद्वेषविषौषधीकलिमलप्रक्षालनस्वर्धुनी-
मोक्षाध्वप्रतिपन्नभव्यभविनां हस्तस्फुरद्दीपिका ।
ज्ञानादित्रयरत्नभूमिरखिलव्यामोहनिर्नाशिनी
यद्वाणीविभवो भवंतु शिवदास्तेऽन्येऽपि तीर्थेश्वराः ॥ ३ ॥

यत्प्रज्ञाप्रसरेऽतिशायिनि तथा प्रालेयशैलोज्ज्वले
जैनी गौरचरत् त्रिपद्यपि यथा सद्यः पदैः कोटिशः ।
अंगोपांगमहोदया समभवत् त्रैलोक्यसंचारिणी
वंद्योऽसौ गणभृज्जगत्त्रयगुरुर्नाम्नेन्द्रभूतिः सताम् ॥ ४ ॥

हस्ताक्षमालामणिसाम्यभाजः सूत्रानुगानुज्ज्वलपूर्णवृत्तान् ।
साधूनिमान् प्रापयतु क्षणेन **गीर्देवता**ऽसौ श्रुतसिंधुपारम् ॥ ५ ॥

प्रत्याशं प्रसरत्प्रभापरिगतो यत्पद्महस्तोऽरुणो
यद्दोषापगमं करोति परितस्तत्सत्यमाभासते ।
आश्चर्यं तु मुनीन्दुतारककविज्योतिःप्रकाशोदयं
धत्ते यत्कुमुदं प्रकाश्य सहसा सौरभ्यलक्ष्म्यास्पदम् ॥ ६ ॥

श्री**मानतुंग**सूरींस्तान् जाड्ये सूर्यानुकारिणः ।
गुरून् निजान् नुमो नित्यं श्रीमतो गणधारिणः ॥ ७ ॥

श्रीगच्छाधिप**मानतुंग**गुरुभिश्चक्रे परार्थोद्यतै-
र्यत्कर्मादिपरार्थसंशयतमःसूर्यप्रभाभासुरम् ।
तत्त्वज्ञानसुधानिधि प्रकरणं यस्मिन् **जयंती**कृत-
प्रश्नेषूत्तरदानवाक्यरचना श्री**वर्द्धमान**प्रभोः ॥ ८ ॥

स्वगुरुबहुमानजलनिधिवेलां दानादिरत्नरमणीयाम् ।
विवृतिं तस्य विधास्ये **सिद्धजयंतीकथां** प्रथयन् ॥ ९ ॥

तत्राधिकृताभीष्टदेवतानमस्कारेण समुन्नतशिरसा मंदरमंथानुकारेण निर्मथितेऽन्तरायनीरधौ समुल्लसिताभीष्टसिद्धिसुधास्वादितः सुमनसां स्यादजरामरपदोपलंभ इति संबद्धार्थभणितिभंगीगंगातरंगिणीपरिष्वंगपवित्रांगतयाऽभिगमनीयताकमनीयता स्यादिति अभिधेयवत्ताव्यक्तिमुक्तावलीव श्रोतृपरिषदो हृदयहारितामात्मन्यादधीतेति फलवत्तया च पक्षपातच्छेकतयाऽऽशुकवीनां सहकारवनमिव सानंदप्रवृत्त्यविकलकारणतां प्रपद्येतेति यशःसौरभोद्गारसारसौजन्यादिगुणगणांभोजवनप्ररोहरमणीयशिष्टसमयसरःप्रतिपालनप्रवणपालिप्रबंधशालिनी चेयं नमस्काराद्यर्थाभिधायिका प्रथमगाथा । यथा—

नमिय नमिरामरेसरसिरसेहरमणिमऊहविच्छुरियं ।
वीरचरणारविंदं **जयंतियापगरणं** वोच्छं ॥ १ ॥

अन्तः—

एवं विणिच्छियट्ठा पहट्ठतुट्ठाऽभिवंदिउं **वीरं** ।
सामन्नमसामन्नं **देवाणंद** व्व काऊणं ॥

तैर्दत्तामुपलभ्य निर्मलकलां श्रीधर्मघोषप्रभु-
भास्वांस्तीव्रतपःप्रतापकलितो जज्ञे ददद्विस्मयम् ।
नानादृप्तकुतीर्थितारकरुचिव्यासप्रहाणोद्यतो
माद्यद्वादिकुशीलकौशिकमदोद्रेकापहारक्षमः ॥ ६ ॥

आदिष्टा जयसिंहसूरिभिरमी चात्मीयशिष्योत्तमा
विख्याता जगति क्षमाधरशिरोऽलंकारलीलास्पृशः ।
पूज्याः शीलगणाह्वया गणभृतो येऽखंडवृत्तोदया
निन्युश्चन्द्र इव प्रकाशपदवीं पूर्णामिमां पूर्णिमाम् ॥ ७ ॥

गच्छेऽस्मिन् प्रसृते क्षमानुगगुणैः शाखाभिरभ्युन्नते
येषां कुंदसमुज्ज्वलेन यशसा पुष्पायितं सर्वतः ।
तद्गंधग्रहणाग्रहैकरसिका भव्यालयोऽहर्निशं
संगीतं प्रथयंति सम्मदरसस्यापानतः स्वेच्छया ॥ ८ ॥

चंचच्चन्द्रकुले चरित्रनृपतेः श्रीराजधान्यामिह
प्रासादेषु महाव्रतेषु सुदुरारोहाग्रभागेष्वियम् ।
येषां कीर्त्तिरमंदमंदरपरिभ्रांतिक्रमोल्लासित-
क्षीराम्भोधिविलोलवीचिरुचिरा नूनं पताकावली ॥ ९ ॥

यद्दीक्षा सुकृतोदयेन कृतिनां दाक्षायणीनायक-
ज्योत्स्नेव प्रमदं विकाश्य कुमुदं दूरे रजांस्यऽस्यति ।
संतापं हरते गुणौघमनघं दुग्धोदधिं वर्धय-
त्यस्मात् संवरवीचिसंचयवशान्मुक्तात्मलाभो भवेत् ॥ १० ॥

सिंहस्यापि लघोः क्रमेण भविता शौर्यं करीन्द्रापहं
बालस्यापि रवेर्महः प्रतिदिनं दृष्टं प्रतापावहम् ।
एवं ज्ञानदृशा विभाव्य वयसि स्वल्पेऽपि तैः श्रीमतां
येषां शीलगणाभिधैः स्वगुरुभिश्चक्रे पदस्थापना ॥ ११ ॥

तेषां चिरं गच्छपतित्वभाजां श्रीमानतुंगाभिधसूरिराजाम् ।
शिष्या बभूवुर्गुणदिव्यरत्नरत्नाकरा वृत्तधरा धरित्र्याम् ॥ १२ ॥

तेषु श्री**मलयप्रभा**ख्यगणभृच्छाखाधिराजोऽजनि
ज्ञानेंदूदयशैलशृंगसुभगोऽनुल्लंघ्यमानोन्नतिः ।
ख्यातो यः सह शेषसूरिभिरिह स्वीयैः क्षमामंडले
सूर्यो द्वादशमूर्त्तितामधिगतो भव्याम्बुजोद्बोधकः ॥ १३ ॥

एवं गुरुपर्वक्रमसंबद्धे जयति **वीरजिनतीर्थे** ।
श्री**मानतुंग**गुरुभिः कृते **जयंत्या** महासत्याः ॥ १४ ॥

प्रश्नोत्तरप्रकरणे परिवाराभ्यर्थने स्वगुरुभक्त्या ।
अविभक्त**धर्मचन्द्रा**भिधगणिना भागिनेयेन ॥ १५ ॥

भणितैः श्री**मलयप्रभ**सूरिभिरेषा विचित्रदृष्टान्तैः ।
संवेगाय यथामति जगति **जयंतीकथा** प्रथिता ॥ १६ ॥

हंसोऽयं गगने प्रभातमुखतः क्रीडासरस्यन्वहं
यावत् सांद्रतमिस्रशैवलमलं दूरे व्युदस्य क्षणात् ।
धत्ते सर्वदिशां मुखांबुजवने संचारलीलायितं
संतोषं सुधियां ददात्वविकलं ताव**ज्जयंतीकथा** ॥

द्वादशवर्षशतेषु श्रीविक्रमतो गतेषु षष्टितमे (१२६०) ।
वर्षे ज्येष्ठे मासे श्रवणे भे कृष्णपंचम्याम् ॥ १ ॥

जीवादिविषयसंशयतमोपहारैकतरणिरुचिरुचिरा ।
योगे चैन्द्रे सिद्धाविदं **जयंतीकथा** रचिता ॥ २ ॥

मोहमहीपतिविजये चतुरंगबलेन शुचिगुणस्यूता ।
इह जगति वैजयंती जयतु **जयंतीकथा** सुचिरम् ॥ ३ ॥ छ ॥ मंगलमस्तु ॥ छ ॥

दिव्यश्रीसदनं सदा क्षितिधराधारः सुपात्रास्पदं
क्षोणीमंडलमंडनं सुविदितः **प्राग्वाटवंशो**ऽस्ति सः ।
यत्र च्छत्रपरम्परावति तते संप्राप्य पर्वस्थितिं
जायंतेऽद्भुतमत्र वांछितफलैः सौहित्यभाजो जनाः ॥ १ ॥

मुक्तावत्तत्र वंशे समजनि विदितो **धाहडः** श्रेष्ठिवर्यः
सद्वृत्तः कांतकांतिः प्रवरगुणगणः प्रास्तनिःशेषदोषः ।

आनंदाधायिमूर्त्तिस्त्रिभुवनभवनोत्संगरंगत्सुकीर्त्तिः
स्फूर्जत्पुण्यप्रबंधोद्भववशविलसत्प्राभवस्फूर्त्तिपूर्त्तिः ॥ २ ॥

नयविनयवितितिविढपितासितांशुसितकीर्त्तिधवलितदशाशः ।
पुण्याचारपवित्रस्तत्पुत्रो **धवल**नामाऽऽसीत् ॥ ३ ॥

अजनीह **मरू**संज्ञा **मरुस्थली**पापपंकजवनस्य ।
तस्य प्रवरा जाया विशुद्धशीला विगतमाया ॥ ४ ॥

तत्पुत्री ठक्कुराणी समभवदसमक्षांतिविस्तीर्णशाला
नाऊनामा शशांकद्युतिधवलगुणैः साधुशस्यैर्विशाला ।
धर्मानुष्ठाननिष्ठाविधिवशविकसत्कीर्त्तिसंभारसारा
प्राज्यस्फूर्ज्जद्विवेकप्रतिहतविततोद्दामदुर्वारमारा ॥ ५ ॥

इतश्च--

संजातोऽत्रैव वंशे निरुपममहिमाभाग्यसौभाग्यभूमिः
श्रीपालठक्कुराग्र्यः प्रथितशुचियशाः पालितप्राज्यनीतिः ।
दिव्यश्रीकेलिगेहं समजनि परमं मंडनं धामलक्ष्म्याः
श्रीदेवी तस्य पत्नी विकृतकलुषतालोलतानां सपत्नी ॥ ६ ॥

तयोः सुतः **शोभनदेव**नामा मुख्यो **यशोदेव** इति द्वितीयः ।
जातोऽभिजातो नृपमान्यतादिगुणैरशेषैर्भुवि सुप्रसिद्धः ॥ ७ ॥

तत्र **शोभनदेव**स्य ठक्कुरस्य गृहाद्द्वयम् ।
सूहव-महणूसंज्ञं **सोढू**नामा सुताः पुनः ॥ ८ ॥

नाऊकायाः पाणिग्रहणं कृतवानसौ **यशोदेवः** ।
तत्रातिरत्नभूतेति **रत्नदेवी**ति विदितेयम् ॥ ९ ॥

या सीतेव कलौ कलंकविकलप्रोल्लासिशीलोज्ज्वला
धर्मानुष्ठितिनिष्ठया त्रिभुवने प्राप्तप्रतिष्ठा हि या ।
लब्धागण्यवरेण्यपुण्यनिवहा या चैत्यकृत्यादिभि-
र्नानास्थानपुरादिधार्मिकसभाप्रख्यातनामा च या ॥ १० ॥

ज्ञानं मोहमहांधकारदलने रत्नप्रदीपायते
ज्ञानं दुर्गतिदुर्गकूपपतने हस्तावलंबायते ।
गंभीरे भववारिधौ भवभृतां ज्ञानं सुपोतायते
ज्ञानं कामितवस्तुलाभविषये सत्कामधेनूयते ॥ ११ ॥

इत्येवं शुभदेशनां बहुविधां श्रुत्वा गुरूणां मुखा-
देषा दोषपराङ्मुखी जिनमते रक्ता विरक्ता भवे ।
सप्तक्षेत्रनिजार्थबीजवपनासक्ता विशेषात् पुन-
र्नानापुस्तकलेखने कृतमतिर्नाऊरिह श्राविका ॥ १२ ॥

इतश्चतुर्भिः संबंधः—

श्रीशीलगणसूरीशपूज्यपट्टप्रतिष्ठितैः ।
बाल्यादपि महापुण्यश्रेण्या नित्यमधिष्ठितैः ॥ १३ ॥

श्रीमानतुंगसूरिभिराराध्यैस्तत्र यज्जयंत्याख्यम् ।
प्रकरणमकारि शुभदं भगवत्यंगान्मनोहारि ॥ १४ ॥

तस्योपरि गुरुभक्त्या विदधे सुधियां मनोरमा वृत्तिः ।
श्रीमलयप्रभसूरिभिरिह या पूज्यैः प्रसन्नतमैः ॥ १५ ॥

तामिह सा नाऊका ज्ञानाराधनधिया सुगुरुभक्त्या ।
लेखितवती गुणवती महासती शुद्धशुभभावा ॥ १६ ॥

यावच्चारुमरीचिसंचयाचिते चंद्रार्कयोर्मंडले
राजेते गगनश्रियो मणिमये दिव्ये चलत्कुंडले ।
ताराश्रेणिरियं पुनः सुकुसुमालंकारशोभावहा
तावत् पुस्तकमेतदद्भुततमं व्याख्यायतां सूरिभिः ॥ १७ ॥

स्वस्ति श्रीविक्रमनरेन्द्रतः संवत् १२६१ वर्षे अश्विनवदि ७ रवौ पुष्यनक्षत्रे शुभयोगे श्रीमदणहिलपाटके महाराजाधिराजश्रीभीमदेवकल्याणविजयिराज्ये प्रवर्त्तमाने श्रीप्राग्वाट-ज्ञातीयश्रेष्ठिधवलमरुपुत्र्या ठ० नाऊश्राविकया आत्मश्रेयोऽर्थं पंडितमुंजालहस्तेन मंकुशिकास्थाने जयंतीवृत्तिपुस्तकं लेखयित्वा श्रीअजितदेवसूरीणां निजभक्त्या समर्पित-मिति ॥ छ ॥ शुभं भवतु । मंगलमस्तु । मंगलं महाश्रीः ॥ छ ॥

*

No. 154 Pravacanasāroddhāraprakaraṇa with Vṛtti
प्रवचनसारोद्धारप्रकरण वृत्तिसहित

Folios – 293
Language – Prakrit & Sanskrit
Author – Nemicandrasūri
Commentator – Siddhasenasūri
Size – 17·2 × 2·5 inches
Condition – Good
Date of
Composition of Vṛtti – 1248 V.S.
Age of MS. – c. First half of 14th cent. V. S.
General Remarks – From Dwāra 67 to Dwāra 142. Folios 41–43, 53, 95, 102, 103, 107, 111, 113, 116–121, 125, 130, 146, 154, 157, 161, 165, 166, 188, 189, 220, 223, 240, 249, 261–275 missing.

आदिः—

इदानीं करणं ति सत्तषष्टं द्वारमाह ।
पिंडविसोही समिई भावण पडिमा य इंदियनिरोहो ।

अन्तः—

तिन्नि सया तेयाला रज्जूणं होंति सव्वलोगम्मि ।
चउरंसं हो....................

*

No. 155 Pravacanasāroddhāraprakaraṇa with Vṛtti
प्रवचनसारोद्धारप्रकरण वृत्तिसहित

Folios – 249
Language – Prakrit & Sanskrit
Author – Nemicandrasūri
Commentator – Siddhasenasūri
Size – 15 × 2 inches
Condition – Good
Date of
Composition of Vṛtti – 1248 V.S.
Age of MS. – c. First half of 14th cent. V. S.
General Remarks – From Dwāra 134 to Dwāra 263. Folio No. 1 missing.

अन्तः—

इदानीं वैनयिकानां द्वात्रिंशद् भेदान् आह–सुरनिवइ इत्यादि गाथाद्वयम् ॥

*

No. 156 Pravacanasāroddhāra Viṣamapadaparyāya
प्रवचनसारोद्धार विषमपदपर्याय

Folios – 187
Language – Sanskrit
Author – Udayaprabhasūri
Age of MS. – c. End of 13th cent. V. S.
Extent – 3202
Size – 17 × 2·5 inches
Condition – Good

आदिः—

प्रवचनसारोद्धारे विषमपदार्थविबोधमाधत्ते ।
श्रीउदयप्रभसूरिः श्रीपार्श्वाधीशमानम्य ॥ १ ॥
सूत्रेणैव गतार्थे व्याख्या पुनरुक्तदोषपोषाय ।
हीनांग इत्यवज्ञा विज्ञैस्तेनात्र नो कार्या ॥ २ ॥
यद्वा सूत्रेणैष सुसूत्रः कार्यो हार इव योजितविमुक्तः ।
यस्माद्विषमपदार्थावबोधसंधिर्दुरधिगम्यः ॥ ३ ॥

*

No. 157 Yogaśāstra-First Four Prakāśas

योगशास्त्रम्—आद्यप्रकाशचतुष्कम्

Folios – 3 to 69
Language – Sanskrit
Author – Hemacandrācārya
Size – 12 × 1·7 inches
Condition – Good
Age of MS. – c. Latter half of 13th cent V. S.

*

No. 158 Yogaśāstram-First Four Prakāśas

योगशास्त्रम्—आद्यप्रकाशचतुष्टयम्

Folios – 40
Language – Sanskrit
Author – Hemacandrācārya
Size – 14 × 1·7 inches
Condition – Good
Age of MS. – 1294 V. S.

अन्तः—

इति परमार्हतश्रीकुमारपालभूपालशुश्रूषिते आचार्यश्रीहेमचन्द्रविरचिते अध्यात्मोपनिषन्नाम्नि संजातपट्टबंधे द्वादशप्रकाशे श्रीयोगशास्त्रे चतुर्थः प्रकाशः ॥ छ ॥ * ॥ छ ॥ संवत् १२९४ वर्षे माघशुदि रवौ पं० देवानंदस्य योग्यं लिखितमिति ॥ छ ॥ * ॥ छ ॥

*

No. 159 Yogaśāstram-First Four Prakāśas

योगशास्त्रम्— आद्यप्रकाशचतुष्टयम्

Folios – 6 to 49
Language – Sanskrit
Author – Hemacandrācārya
Size – 11·7 × 1·7 inches
Condition – Fair
Age of MS. – c. Latter half of 13th cent. V. S.

*

No. 160 Yogaśāstram-with his own Vṛtti

योगशास्त्रम्—स्वोपज्ञवृत्तियुक्तम्

Folios – 393
Language – Sanskrit
Author – Hemacandrācārya
General Remarks – A corrected manuscript

Extent – Granthas 12000
Size – 30·2 × 2·2 inches
Condition – Good
Age of MS. – V.S. 1251

आदिः—

॥ अर्हम् ॥ प्रणम्य सिद्धाद्भुतयोगसम्पदे श्रीवीरनाथाय विमुक्तिशालिने ।
स्वयोगशास्त्रार्थविशेषनिर्णयो भव्यावबोधाय मया विधास्यते ॥ १ ॥

तस्य चायमादिश्लोकः—

नमो दुर्वाररागादिवैरिवारनिवारिणे ।
अर्हते योगिनाथाय महावीराय तायिने ॥ १ ॥

अत्र महावीरायेति विशेष्यपदम् ।

अन्तः—

इदानीं श्रुताम्भोधेरधिगमादिति यन्मुखे प्रतिज्ञातं तन्निर्वाहेणानूद्योपसंहरति ॥ छ ॥

या शास्त्रात् सुगुरोर्मुखादनुभवाच्चाज्ञायि किंचित् कचि-
द्योगस्योपनिषद् विवेकिपरिषच्चेतश्चमत्कारिणी ।
श्री**चौलुक्यकुमारपालनृपते**रत्यर्थमभ्यर्थना-
दाचार्येण निवेशिता पथि गिरां श्री**हेमचंद्रेण** सा ॥

या योगस्योपनिषद्रहस्यमज्ञायि ज्ञाता । कुतः, शास्त्रात् द्वादशाङ्गादागमात् । सुगुरोः सदागमव्याख्यातुर्मुखात् साक्षादुपदेशात् । अनुभवात् स्वसंवेदनरूपात् किंचिदिति स्वप्नज्ञानानुसारेण । कचिदिति एकत्र सर्वस्य ज्ञातुमशक्यत्वात् प्रदेशभेदे कचन । उपनिषदमेव विशिनष्टि । विवेकिनां योगरुचीनां या परिषत् सभा तस्या यच्चेतस्तच्चमत्करोतीत्येवंशीला सा योगस्योपनिषत् । श्री**चौलुक्यो** यः **कुमारपाल**नृपतिस्तस्यात्यर्थमभ्यर्थनया । स हि योगोपासनप्रियो दृष्टयोगशास्त्रान्तरश्च इति स पूर्वेभ्यो योगशास्त्रेभ्यो विलक्षणं योगशास्त्रं शुश्रूषमाणोऽत्यर्थमभ्यर्थितवान् । ततस्तदभ्यर्थनतो वचनस्यागोचराऽपि उपनिषत् गिरां पथि निवेशितवानाचार्यश्री**हेमचन्द्र** इति शुभम् ॥

श्री**चौलुक्य**क्षितिपतिकृतप्रार्थनाप्रेरितोऽहं,
तत्त्वज्ञानामृतजलनिधे**र्योगशास्त्र**स्य वृत्तिम् ।
स्वोपज्ञस्य व्यरचयमिमां तावदेषा च नन्द्याद्,
यावज्जैनप्रवचनवती भुर्भूवःस्वस्त्रयीयम् ॥

संप्रापि योगशास्त्रात्तद्विवृत्तेश्चापि यन्मया सुकृतम् ।
तेन जिनबोधिलाभप्रणयी भव्यो जनो भवतात् ॥ छ ॥

इति परमार्हतश्री**कुमारपाल**भूपालशुश्रूषिते आचार्यश्री**हेमचन्द्र**विरचिते अध्यात्मोपनिषन्नाम्नि संजातपट्टबंधे श्री**योगशास्त्रे** स्वोपज्ञं द्वादशप्रकाशविवरणम् ॥ छ ॥ * ॥ छ । ग्रन्थ श्लोक १२००० । संपूर्णं योगशास्त्रविवरणमिति ॥ छ ॥ मंगलं महाश्रीः ॥ छ ॥

भृङ्गीणामिव पक्षपातललितैर्लीलागृहं सुश्रियां
सुच्छायो विततोऽतिविस्मयकरः **श्रीमालवंशो**ऽस्त्यसौ ।
उद्यत्पर्वमनोहरे क्षितिधरप्राप्तप्रतिष्ठोदये
यत्र च्छत्रपरंपरा ननु परादृश्यन्त एवानिशम् ॥ १ ॥

आसीद्वंशे वरगुणगणे तत्र मुक्तानुकारी
कान्त्युल्लासैर्निरुपमतमः साधुवृत्तानुसारी ।
शुद्धध्यानोपचितसुकृतो देवपूजादिनिष्ठः
श्रेष्ठी श्रेष्ठः सुनयविनयैः **साभदेवो** गरिष्ठः ॥ २ ॥

पासिलाख्यः सुतस्तस्मादत्यद्भुतसुवैभवात् ।
सुमनोवर्गमुख्योऽभूज्जयन्त इव वासवात् ॥ ३ ॥

अगण्यपुण्यलावण्या तस्य **पूनाविनामिका** ।
सीतेव रामचन्द्रस्य जाता पत्नी पतिव्रता ॥ ४ ॥

तौ **सर्वदेव-साभाख्यौ** तत्कुलव्योममंडनम् ।
जज्ञाते ज्ञातमाहात्म्यौ चंद्रार्काविव विश्रुतौ ॥ ५ ॥

एतयोः **सोहिणि**र्भग्नी भग्नकंदर्पशासना ।
जिनशासनधरा जज्ञे सज्ज्ञानाम्भोजदीर्घिका ॥ ६ ॥

श्रेष्ठिनः **सर्वदेवस्य पार्श्वनागः** सुतोऽजनि ।
लक्ष्मीकुक्षिभवा शान्ता तस्य **थामिणि**रात्मजा ॥ ६ ॥

जाते सधर्मचारिण्यौ धर्मकर्मातिकर्मठे ।
साभाकस्य सदा भक्ते **वीरी-वयजसंज्ञिते** ॥ ७ ॥

वीरीकायाः सुते जाते जातिश्लाघ्ये शमान्विते ।
सीता-जास्यौ जिनाधीशधर्माराधनतत्परे ॥ ८ ॥

सत्पुत्रस्तत्र **सीताया आसदेवाभिधो**ऽभवत् ।
ततो भूतौ सुतावाभू-**शोभनदेवनामकौ** ॥ ९ ॥

अभूतां नंदनौ **जास्यास्तुवूटडि-यशोधरौ** ।
जिंदा-यशःकुमाराख्यौ बभूवतुस्तयोः सुतौ ॥ १० ॥

वयजाख्या तु तत्पत्नी पंचाऽसूत सुतोत्तमान् ।
कुंतीव पांडवान् पांडुयशःशुभ्रितभूतलान् ॥ ११ ॥

तेषामा**म्रप्रसादाख्य** आद्यो **देवधर**स्ततः ।
रामदेवस्ततश्चां**ड्र-यशोधवल**संज्ञितौ ॥ १२ ॥

पंचाप्यद्भुतधर्मकर्मनिरताः पंचापि पुण्यांचिताः
पंचाप्युग्रभवप्रपंचविमुखाः पंचापि सत्यप्रियाः ।
एते पंचमहाव्रतैकरुचयः पंचापि शुद्धाशयाः
प्रापुः पञ्चजनौघमौलितिलकाः पंचापि कीर्तिं पराम् ॥ १३ ॥

अभूदाम्रप्रसादस्य सज्जनी वरगेहिनी ।
ज्ञानविज्ञानयोः पात्रं तनूजः **सोहड**स्तयोः ॥ १४ ॥

जाया **देवधर**स्यासीत् श्रेष्ठिनः श्रेष्ठतानिधेः ।
सांतूकायाः सुता **माढूः** शमकैरवकौमुदी ॥ १५ ॥

आभडो नरसिंहश्च जज्ञिरे सूनवस्तयोः ।
जगदेवाख्य-लाखाक-चाहडाः श्रुतशालिनः ॥ १६ ॥

आद्या **प्रियमती** नामा संजाता तदनु **कुमरदेवी**ति ।
लध्वी त्व**न्निहवदेवी** वधूटिका तस्य विनययुता ॥ १७ ॥

भार्याऽभूद्रा**मदेव**स्य **पदमी** नंदनास्त्वमी ।
शंवो वयरसिंहश्च **पुण्य**श्च **जयन्तः** सुताः ॥ १८ ॥

अन्यच्च—

येन जिग्ये जगद्देवगुरुभक्त्याऽखिलं भृशम् ।
जगदेवस्य तस्यासीद्दैवाद् ग्लानिकारणम् ॥ १९ ॥

इतश्चतुर्भिः सम्बन्धः—

ज्ञात्वा येन लघीयसाऽपि सहसा स्वस्यान्तकालं क्षणा-
दानाय्य व्रतिनः स्वयं तदखिलं कृत्वाऽन्त्यकृत्यं स्फुटम् ।
त्यक्त्वा स्नेहमशेषमात्मवदनेनोच्चार्य धर्मव्ययं
जिग्ये मोहमहामहीपतिरतिप्राज्यप्रभावोऽप्यसौ ॥ २० ॥

आबाल्यादपि येन पूर्णविधिना भक्त्याऽर्चितः श्रीजिन-
स्तात्पर्यादतिसेविताः सुगुरवोऽभ्यस्तं च शास्त्रं परम् ।
आत्मीयैर्विनयादिभिर्वरगुणैराचन्द्रकालं कलौ
चन्द्रांशूज्ज्वलकान्तकीर्त्तिरतुला स्वल्पैर्दिनैरर्जिताः ॥ २१ ॥

श्री**योगशास्त्रवृत्ते**र्**देवधरे**णात्मपुत्रसहितेन ।
निस्संगचित्तमुनिवत् सावद्यारंभरहितेन ॥ २२ ॥

साधुजनजनिततोषं निर्दोषं पुस्तकप्रवरमेतत् ।
तस्यात्मसुतस्य **जगद्देवस्य** श्रेयसेऽलेखि ॥ २३ ॥

यद् दोषैरकलंकितं गुणगणैर्युक्तं मनोहारिभि-
र्नित्याभ्यासवशेन निर्वृतिकरं दिव्योक्तसाधुक्रियम् ।
श्रीभूपाल**कुमारपाल**सहितं श्री**हेमचन्द्र**प्रभोः
कर्मव्याधिविबाधकं विजयतां तद् **योगशास्त्रं** सदा ॥ २४ ॥

सूर्याचन्द्रमसौ यावद् द्योतयन्ति भुवं रुचा ।
अश्रान्तं पुस्तकं तावत् कोविदैर्वाच्यतामिदम् ॥ २५ ॥ छ ॥

ॐ ॥ स्वस्ति श्रीविक्रमनृपतेः संवत् १२५१ वर्षे कार्त्तिक सुदि १२ शुक्रे रेवति-नक्षत्रे सिद्धयोगे महाराजश्री**भीमदेव**विजयिराज्ये अवनिवनिताप्रशस्तकस्तूरिकातिलकाय-मान**लाटदेश**ालंकारिणि सकलजनमनोहारिणि विविधधार्मिकविराजमाने **दर्भवती**स्थाने **श्रीमाल**वंशीय श्रे० **साभा**नंदनेन जगदानंदनेन निर्मलतमसम्यक्त्वधरेण श्रे० **देवधरेण** सकलधर्मकर्माविहितेन ठ० **आभड-नरसिंहा**दिसुतसाहितेन निजपुत्र**जगद्देव**श्रेयोनिमित्तं श्री**वटपद्रकपुर**प्रसिद्धप्रबुद्ध पं० **केशव**सुत पं० **वोसरि**हस्तेनाशेषविशेषज्ञचेतश्चमत्कारकारी-दमप्रतिमप्रतापश्रीजिनशासनप्रभावकश्री**कुमारपाल**भूपालविधापितस्य श्री**हेमचन्द्र**सूरिरचितस्य श्री**योगशास्त्रस्य वृत्ति**पुस्तकं लिखितमिति । मङ्गलं महाश्रीः । शुभं भवतु लेखकपाठक-वाच[का]नामिति ॥ छ ॥ * ॥ छ ॥

*

No. 161 : Yogaśāstra-with his own Commentary

योगशास्त्रम्—स्वोपज्ञटीकासहितम्

Folios – 323
Language – Sanskrit
Author – Hemacandrasūri
Extent – Granthas 12000
Size – 29 × 2·2 inches
Condition – Good

अन्तः—

अस्तीह श्रेष्ठपर्वप्रचयपरिचितः क्ष्माभृदाप्तप्रतिष्ठः ० इत्यादि
(जुओ क्रमांक १)........
एवं निशम्य सम्यक् ततश्च निजभुजसमर्जितधनेन ।
श्रीयोगशास्त्रवृत्तेः पुस्तकं लेखयामास ॥ २० ॥........

*

No. 162 : Yogaśāstra-with his own Vivaraṇa

योगशास्त्रम्—स्वोपज्ञविवरणसहितम्

Folios – 258
Language – Sanskrit
Author – Ācārya Hemacandra
Size – 14 × 1·5 inches
Condition – Good
Age of MS. – c. Latter half of 13th cent. V.S.

General Remarks – Contains First Prakāśa only—incomplete.

*

No. 163 : Yogaśāstra-with his own Vivaraṇa

योगशास्त्रम्—स्वोपज्ञविवरणसहितम्

Folios – 242
Language – Sanskrit
Author – Hemacandrācārya
Age of MS. – V. S. 1292
Extent – Granthas 3100
Size – 14·2 × 2·2 inches
Condition – Good

General Remarks – Contains the Second Prakāśa only. Folios 43–45, 47–50, 52–55, 57, 60–66, 70, 71, and 215 missing.

अन्तः—

इति परमार्हतश्रीकुमारपालभूपालशुश्रूषिते आचार्यश्रीहेमचंद्रविरचितेऽध्यात्मोपनिषन्नाम्नि संजातपट्टबंधे श्रीयोगशास्त्रे स्वोपज्ञं द्वितीयप्रकाशविवरणं ॥ छ ॥ ग्रंथाग्रं ३१०० मंगलं महाश्रीः ॥ छ ॥ छ ॥ भद्रम् ॥

आसीच्चन्द्रकुलांबरैकतरणिः श्रीमानदेवाभिध-
स्तद्वंशे प्रभुमानतुंगगणभृत् प्राज्यप्रभावः प्रभुः ।

तत्राजायत **बुद्धिसागरगुरुः प्रद्युम्नसूरि**स्तत-
स्तच्छिष्योऽजनि **देवचंद्र**गणभृद् गच्छाग्रणीर्विश्रुतः ॥ १ ॥

श्रीदेवचंद्रस्य मुनीश्वरस्य जातौ सुशिष्यौ जगति प्रसिद्धौ ।
श्रीमानदेवः प्रथमो गणेशः **श्रीपूर्णचंद्रो** गणभृत्तथाऽन्यः ॥ २ ॥

यः सैद्धांतिकमौलिभूषणमणिर्विद्वज्जनाग्रेसरः
संतोषोत्तमरत्नराजिततनुः **श्रीमानदेव**प्रभुः ।
यच्चेतः कलयाऽपि नो विलिखितं सल्लापलीलावती-
वेल्लल्लोचनचारुवीक्षितशरश्रेणीभिरात्मोद्भवः ॥ ३ ॥

श्रीपूर्णचंद्रसूरेर्गौर्वादिगोवृंदनाशिनी ।
ब्रह्मनिघ्नाऽपि साऽव्याद्वो याऽसूत परमं वृषं ॥ ४ ॥

श्रीमानदेवसूरेः पट्टेऽजनि **मानतुंगसूरि**गुरुः ।
विधिरिव भवांतकारी नरकद्वेषी स विष्णुरिव ॥ ५ ॥

अन्यच्च—

धर्कटवंशसुधानिधिचंद्रः श्रेष्ठी **गणियाको** निस्तंद्रः ।
तस्य **गुणश्रीः** समजनि जाया दक्षसुतेव सदैव विमाया ॥ ६ ॥

तस्यांगजैका सुमहत्तरायाः **प्रभावतीसंज्ञमहत्तरायाः** ।
पार्श्वेऽग्रहीत् पंच महाव्रतानि **प्रद्युम्नसूरेः** सुगुरोः करेण ॥ ७ ॥

जगश्रीरुदयश्रीः श्रीचारित्रश्रीमहत्तरा ।
क्रमेण तासां सर्वासां पादपद्ममधुव्रता ॥ ८ ॥

सा निर्मलमतिगणिनी रम्यां श्री**योगशास्त्र**सद्वृत्तेः ।
द्वैतप्रकाशखंडस्य पुस्तिकां लेखयामास ॥ ९ ॥

श्रीमानतुंगसूरेः पट्टस्थितपद्मदेवसूरीणाम् ।
तां प्रवचनरसपात्रं प्रददौ पुण्याय पुण्यतराम् ॥ १० ॥

कल्याणाद्रिनृपो धराधरसुता जाया कुरू मंत्रिणो
वृद्धा वृद्धनगाञ्जनास्तदपरे वक्षारसाराकराः ।
चंद्रादित्यवरौ पदातिभगणाः साम्राज्यमेतत् क्षितौ
यावत्तिष्ठति तावदत्र विबुधैर्वाच्या सदा पुस्तिका ॥ ११ ॥

संवत् १२९२ वर्षे कार्त्तिक शुदि ८ रवौ धनिष्ठानक्षत्रे **योगशास्त्रवृत्तिद्वितीय-प्रकाशस्य**[पुस्तिका] लिखितेति । शुभं भवतु ॥ छ ॥

*

No. 164 : Yogaśāstra-with his own Vṛtti

योगशास्त्रम्—स्वोपज्ञवृत्तिसहितम्

Folios – 228 to 452
Language – Sanskrit
Author – Hemacandrācārya
Age of MS. – V.S. 1260
Extent – Granthas 3800
Size – 14.7 × 1.5 inches
Condition – Good

General Remarks – Contains the third Prakāśa only. Folio no. 451 is marked thus in the margin : ास्ता
C
१

अन्तः—

........तश्रीकुमारपालभूपालशुश्रूषिते आचार्यश्रीहेमचन्द्र........बंधे **श्रीयोगशास्त्रे** स्वोपज्ञतृतीयप्रकाशविवरणम् ॥ ग्रं. ३८०० ॥ छ ॥ सं. १२६० अश्विन शु. ५ लिखितेयम् ॥

*

No. 165 : Yogaśāstra with his own Vṛtti

योगशास्त्रम्—स्वोपज्ञवृत्तिसहितम्

Folios – 240
Language – Sanskrit
Author – Hemacandrācārya
Age of MS. – c. Latter half of 13th cent. V. S.
Extent – Granthas 2000
Size – 12.2 × 1.7 inches
Condition – Good

General Remarks – Contains the fourth Prakāśa only.

*

No. 166 : Yogaśāstra-with his own Commentary

योगशास्त्रम्—स्वोपज्ञटीकासहितम्

Folios – 118
Language – Sanskrit
Age of MS. – c. Latter half of 13th cent. V. S.
Extent – Granthas 1300
Size – 15.7 × 2 inches
Condition – Good

General Remarks – Complete from the beginning of the fifth Prakāśa.

*

No. 167 : Yogaśāstra-with his own Vṛtt

योगशास्त्रम्—स्वोपज्ञवृत्तिसहितम्

Folios – 343
Language – Sanskrit
Author – Hemacandrācārya
Age of MS. – c. Latter half of 13th cent. V. S.
Extent – Granthas 3300
Size – 15·5 × 1·5 inches
Condition – Good
General Remarks – Contains the Second Prakāśa only. The first 11 folios and folio Nos. 330 to the end are injured. Folios 330 onwards are written on paper and are much injured. Folio No. 330 contains the following marking in the margin : सा ला ०

*

No. 168 : Yogaśāstra–with his own Vivaraṇa

योगशास्त्रम्—स्वोपज्ञविवरणसहितम्

Folios – 8 to 423
Language – Sanskrit
Author – Hemacandrācārya
Age of MS. – c. Latter half of 13th cent. V. S.
Extent – Granthas 3800
Size – 15·5 × 1·5 inches
Condition – Good
General Remarks – Contains the third Prakāśa only. Folios 108–111, 115, 116, 129, 131, 132, 134–150, 219–247 missing.

*

No. 169 : Yogaśāstra–Commentary Notes

योगशास्त्र—टीकाटिप्पन

Folios – 24
Language – Sanskrit
Age of MS. – c. First half of 14th cent. V. S.
Size – 14·2 × 2·2 inches
Condition – Good

आदिः—

॥ अर्हम् ॥ **योगशास्त्रस्य टीकाटिप्पनकम्** ॥ सोढेति कथं सहिष्यते । सरस्यामिति अखातसरसि । विदांकरोतु जानातु । प्रणेमे नमस्कृतः । वेधसे द्वादशांगस्यादिकृते । लोकप्रदीपाय भव्यसत्त्वा लोकः ।

अन्तः—

अर्थपरिसमाप्तिकं वाक्यपदमुच्यते ॥ छ ॥ मंगलं महाश्रीः ॥ छ ॥ शुभं भवतु संघस्य लेखकपाठकयोरेव ॥

*

No. 170 : Śrāddhadinakṛtyaprakaraṇa with his own Vṛtti

श्राद्धदिनकृत्यप्रकरणम्—स्वोपज्ञवृत्तिसहितम्

Folios – 267
Language – Prakrit & Sanskrit
Author & Commentator – Devendrasūri
Age of MS. – c. 14th Century V. S.

Extent – Granthas 13000
Size – 32.5 × 2.2 inches
Condition – Good

आदिः—

॥ ॐ नमः सर्वज्ञाय ॥

गोभिर्येन जगत्त्रयेऽपि निखिलद्रव्यप्रकाशः सदा
चक्रे जाड्यतमोभिदा भवभृतां दोषापहारस्तथा ।
तं नत्वा जिनवीरमर्कमतुलं सूत्रात्तथाम्नायतः
श्राद्धानां दिनकृत्यसूत्रविवृतिं वक्ष्ये सुबोधामहम् ॥

तत्रादौ शिष्टसमयपरिपालनार्थं मंगलादिचतुष्टयाभिधायकं सूत्रकृदेव प्रस्तावनावृत्तमाह ।

वीरं नमेऊण तिलोयभाणुं विसुद्धनाणं सुमहानिहाणं ।
वोच्छामि सड्ढाण दिणस्स किच्चं जिणिंदचंदाण य आगमाओ ॥ १ ॥

वीरं नत्वा श्राद्धानां दिनकृत्यं वक्ष्ये इति समुदायार्थः ।

अन्तः—

सर्वोपसंहारार्थमाह

अयाणमाणेण जिणुत्तमाणं मयं महत्थं मइविब्भमेणं ।
जं मे विरुद्धं इह तस्स वुत्तं तं मज्झ मिच्छामिह दुक्कडं ति ॥ ४४ ॥

पाठसिद्धम् ॥

सिद्धान्ततत्त्वामृतपूरपानात् प्रस्ताव एषोऽष्टमको मयोक्तः ।
उच्चन्द्रकाले शुभसंज्ञिधर्मे सच्चिंतनार्थो दिनकृत्यवृत्तौ ॥ १ ॥

इति **श्रावकदिनकृत्यविवरणे** विधिशयनादिद्वारषट्कव्यावर्णनो नामाष्टमः प्रस्तावः समाप्तः । **तत्समाप्तौ च समाप्तेयं श्रावकदिनकृत्यसूत्रवृत्तिः ।**

जीयात् श्रीवर्धमानस्य तीर्थं सुरसरित्सुखम् ।
पवित्रं विबुधैः सेव्यं पंकतृष्णापहं च यत् ॥ १ ॥

गौतमादनु तत्राभूत् श्रुतगंगाहिमाचलः ।
आद्यो युगप्रधानानां **सुधर्मा** गणभृद्वरः ॥ २ ॥

इतश्च केवली **जंबूः प्रभवः** श्रुतकेवली ।
शय्यंभवो यशोभद्रः संभूतविजयोऽपि च ॥ ३ ॥

भद्रबाहुः स्थूलभद्रस्ततोऽपि दशपूर्विणः ।
महागिरि-सुहस्त्याद्या वज्रांता बहवोऽभवन् ॥ ४ ॥

ततोऽभूद्**वज्रसेन**र्षिर्**वज्रशाखा** ततोऽपि च ।
गणश्च **कोटिका**भिख्यः कुलं **चंद्रकुलं** तथा ॥ ५ ॥

तत्र क्रमेण **चित्रावालक**गच्छो बभूव सुविदितः ।
श्री**भुवनचंद्र**सूरिसूत्रामात् भव्यपद्मरविः ॥ ६ ॥

तच्छिष्यरत्नमभवन् भुवनप्रसिद्धाश्चारित्रपात्रमखिलश्रुतपारमाप्ताः ।
गांभीर्यमुख्यगुणरत्नमहासमुद्राः श्री**देवभद्र**गणिमिश्रसुनामधेयाः ॥ ७ ॥

तत्पादांबुजरोलंबा निरालंबा वपुष्यपि ।
अभूवन् भूरिभावाढ्याः श्री**जगच्चन्द्रसूर**यः ॥ ८ ॥

देवेन्द्रसूरिसंज्ञस्तेषामार्यो बभूव शिष्यलवः ।
श्री**विजयचन्द्र**सूरिस्तथा द्वितीयो गुणैस्त्वाढ्यः ॥ ९ ॥

चक्रे भव्यावबोधाय संप्रदायात्तथाऽऽगमात् ।
सच्छ्राद्धदिनकृत्यस्य वृत्ति**र्देवेन्द्रसू**रिभिः ॥ १० ॥

श्री**विजयचन्द्र**सूरिप्रमुखैर्विद्वद्गणैर्गुणगरिष्ठैः ।
स्वपरोपकारनिरतैस्तदैव संशोधिता चेयम् ॥ ११ ॥

प्रथमां प्रतिमप्रतिमप्रतिभाप्रतिहस्तितत्रिदशसूरिः ।
श्री**हेमकलश**नामा सदुपाध्यायो लिलेखास्याः ॥ १२ ॥

यच्चेह समयहीनं मतिमांद्यात् किमपि विरचितं शास्त्रे ।
क्षंतव्यं तत्कविभिः कृपापरैर्मयि विशोध्यं च ॥ १३ ॥

यावज्जिनमतमेतज्जगतोऽप्युपकर्तृ विजयते पृथ्व्याम् ।
तावत्त्रींदुसहस्री १३००० जीयाद्वृत्तिः कृतानंदा ॥ १४ ॥ छ ॥

॥ ॐ ॥

नमः श्रीवर्द्धमानाय **वर्द्धमानाय** वेदसा ।
वेदसारं परं ब्रह्म ब्रह्मवन्नस्थितिश्च यः ॥ १ ॥

स्वबीजमुप्तं कृतिभिः कृषीवलैः क्षेत्रेषु सिक्तं शुभभाववारिणा ।
क्रियेत यस्मिन् सफलं शिवश्रिया पुरं तदाभाति **दयावटा**भिधम् ॥ २ ॥

ख्यातस्तत्रास्ति वस्तुप्रगुणगुणगणः प्राणिरक्षैकदक्षः
सज्ज्ञाने लब्धलक्ष्यो जिनवचनरुचिश्चंचदुच्चैश्चरित्रः ।
पात्रं पात्रैकचूडामणिजिनसुगुरूपासनावासनायाः
संघः सुश्रावकाणां सुकृतमतिरमी संति तत्रापि मुख्याः ॥ ३ ॥

होनाकः सज्जनश्रेष्ठः श्रेष्ठी **कुमरसिंहकः** ।
सोमाकः श्रावकश्रेष्ठः शिष्टधी**ररिसिंहकः** ॥ ४ ॥

कडुयाकश्च सुश्रेष्ठी **सांगाक** इति सत्तमः ।
खीम्वाकः सुहडाकश्च धर्मकर्मैककर्मठः ॥ ५ ॥

एतन्मुखः श्रावकसंघ एषोऽन्यदा वदान्यो जिनशासनज्ञः ।
सदा सदाचारविचारचारुक्रियासमाचारशुचिव्रतानाम् ॥ ६ ॥

श्री**मज्जगचंद्र**मुनींद्रशिष्यः श्रीपूज्य**देवेन्द्रमुनी**श्वराणाम् ।
तदाद्यशिष्यत्वभृतां च **विद्यानंदा**ख्यविख्यातमुनिप्रभूणाम् ॥ ७ ॥

तथा गुरूणां स्वगुणैर्गुरूणां श्री**धर्मघोषा**भिधसूरिराज्ञः ।
सद्देशनामेवमपापभावां शुश्राव भावावनतोत्तमांगः ॥ ८ ॥

विषयसुखपिपासोर्गेहिनः क्वास्ति शीलं
करणवशगतस्य स्यात्तपो वाऽपि कीदृग् ।
अनवरतमदभ्रारंभिणो भावनाः का-
स्तदिह नियतमेकं दानमेवास्य धर्मः ॥ ९ ॥

किंच—

धर्मः स्फूर्ज्जति दानमेव गृहिणां ज्ञानाभयोपग्रहै-
स्त्रेधा तद्वरमाद्यमत्र यदितो निःशेषदानोदयः ।

ज्ञानं चाद्य न पुस्तकैर्विरहितं दातुं च लातुं च वा
शक्यं पुस्तकलेखनेन कृतिभिः कार्यस्तदर्थोऽर्थवान् ॥ १० ॥
श्रुत्वेति संघसमवायविधीयमानज्ञानार्चनोद्भवधनेन मिथः प्रवृद्धिम् ।
नीतेन पुस्तकमिदं श्रुतकोशवृद्ध्यै बद्धादरश्चिरमलेखयदेष हृष्टः ॥ ११ ॥
यावज्जिनमतभानुः प्रकाशिताऽशेषवस्तुविस्तारः ।
जगति जयतीह पुस्तकमिदं बुधैर्वाच्यतां तावत् ॥ १२ ॥ छ ॥
ग्रंथाग्रं १३००० प्रमाणं ॥ मंगलं महाश्रीः ॥ छ ॥
लेखकपाठकदाताराः समस्तसंघदीर्घायुर्भवतु ॥ छ ॥
यादृशं पुस्तके दृष्ट्वा तादृशं लिखितं मया ।
यदि शुद्धमशुद्धं वा मम दोषो न दीयते ॥ १ ॥
शिवमस्तु सर्वजगतः परहितनिरता भवंतु भूतगणाः ।
दोषाः प्रयांतु नाशं सर्वत्र सुखी भवतु लोकः ॥ २ ॥
भग्नपृष्ठिकटिग्रीवास्तब्धदृष्टिरधोमुखम् ।
कष्टेन लिखितं शास्त्रं यत्नेन प्रतिपालयेत् ॥ ३ ॥ छ ॥

*

No. 171 : Śrāddhadinakṛtyaprakaraṇa–with his own Vṛtti

श्राद्धदिनकृत्यप्रकरणम्—स्वोपज्ञवृत्तिसहितम्

Folios – 356
Language – Prakrit & Sanskrit
Author & Commentator – Devendrasūri
Age of MS. – c. First half of 15th cent. V. S.
Extent – Granthas 13000
Size – 34·5 × 2·2 inches
Condition – Good

अंतः—

तावत्त्रींदुसहस्री जीयाद् वृत्तिः कृतानंदा ॥ १४ ॥ छ ॥
श्रीमद्देवेन्द्रसूरेश्चरणसरसिजोपास्तिहंसायमानः
श्रीविद्यानंदसूरिस्तदनु मुनिपतिर्धर्मघोषाख्यसूरिः ।
त्रैलोक्यख्यातकीर्त्तिर्विमलगुणगणावासमाद्यो मुनीनां
सूरिः सोमप्रभाख्यः शमदममहिमाधीनिधिः साधुराजः ॥ १ ॥
तस्याऽभवच्च विमलप्रभसूरिराद्यो
श्रेष्ठो गुणैर्यतिपतिर्गरिमागरिष्ठः ।

आनंदसूरिरभवत् परमोपगूढः
सूरिव्रजप्रथितकीर्त्तिरथ द्वितीयः ॥ २ ॥
पद्मतिलकगुरुरप्यतोऽभवद् ज्ञानदर्शनचरित्रसुंदरः ।
सूरिराड् विजयते चतुर्थकः सोमतिलकगुरुरत्र विश्रुतः ॥ ३ ॥
ऊकेशवंशतिलकं श्रीशांवरगोत्रमंडनं परमम् ।
पासलश्रेष्ठीः समभूज्जिनसमयरतो गुणमहीयान् ॥ ४ ॥
तस्यान्वये श्रावकमौलिरत्नं पुराऽजनि श्रीअरसीहसाधुः ।
तस्याऽऽसतां द्वौ तनयौ गुणज्ञौ क्षे........जिनराजभक्तौ ॥ ५ ॥
श्रीआसपालस्य सुता अभूवन् पंच पृथिव्यां प्रथिताश्चरित्रैः ।
अदभ्रबुद्धिः प्रथमोऽभ्रसंज्ञः सद्दर्शनस्थः किल धीसलोऽन्यः ॥ ६ ॥
सामंतसिंहो मतिमांस्तृतीयः ततश्चतुर्थो विजयाद्यसिंहः ।
अथार्जुनाख्यः किल पंचमोऽपि पंचाऽभ्रसाधुस्तनयानसूत ॥ ७ ॥
आद्योऽभवद्देल्हणनामधेयः स्तंभाभिधोऽन्यो जगसीहनाम ।
तुर्योऽथ धीमान् किल पासदेवो झाझाभिधानः प्रथितोऽपरश्च ॥ ८ ॥
अभ्रांगजो देल्हण एष भक्त्यां तातस्य पुण्योदयवर्द्धनाय ।
जिनागमाराधनतत्परोऽमुमलेखयत् पुस्तकमादरेण ॥ ९ ॥

*

No. 172 : Darśanaśudhiprakaraṇa with Commentary—Samyaktvaśuddhi-prakaraṇa with Commentary

दर्शनशुद्धिप्रकरणम् सटीकम्—सम्यक्त्वशुद्धिप्रकरणम् सटीकम्

Folios – 283
Language – Prakrit & Sanskrit
Author – Candraprabhasūri
Commentator – Vimalagaṇi
General Remarks – Last five folios are broken.

Size – 28 × 2.2 inches
Condition – Good
Date of Composition of Commentary – V. S. 1184
Age of MS. – c. First quarter of the 13th cent. V.S.

आदिः—

॥ नमः श्रीसर्वज्ञाय ॥

चंचचंद्रमरीचिचारुरुचिरा विश्वंभरा राजते
कीर्त्तिर्विष्टपचंद्रशेखरशशी शीतांशुशीतत्विषम् ।

यः शुद्धाशयशुद्धबुद्धिविभवो धीरो धिनोत्युद्धवं
धीरं नौमि नमत्सुरासुरशिरोघृष्टांह्रिविश्वाग्रणीः ॥ १ ॥

येषामास्यारविंदागमसुपरिमलास्वादमिथ्यालिमाला-
मत्ता मूकाऽपि धत्ते मधुरमुखरतामेवमंह्रिप्रसादः ।
चंचत्स्वर्गापवर्गप्रभवसुसुखदो देहिनां भानवो ये
भासंते चारुगोभिस्त्रिभुवनमखिलं लीलया कामदाभिः ॥ २ ॥

तेषां परमगुरूणां नत्वा पदपंकजं स्फुटां वक्ष्ये ।
वृत्तिं दर्शननाम्नः शास्त्रस्य हितां च सुखबोधाम् ॥ ३ ॥

इह हि भीमभवाटवीभ्रमणभयोद्भ्रान्तमानसस्य नारकतिर्यग्नरामरचतुर्गतिगतातिकटुक-शारीरिकमानसानेकदुःखविच्छेदचिकीर्षोः । दुष्टपुष्टश्लिष्टातिक्लिष्टाष्टकर्मवनगहननिर्दहनबुद्ध्या अतिशयितनरनरेश्वरखेचरखेचरेश्वरचक्रचक्रवर्त्तिसुरासुरसमूहनाकिनायकनिरुपमसुखसंदोहदायि-विशुद्धसिद्धिसौधमध्याध्यासनावंध्यनिबंधनधर्मसंसाधनधेयाधर्मकृत्येषु प्रवर्त्तमानस्य । सामा-न्येनातिधर्मलिप्सोः । अनादिकाललीनमोहवासनावशगतनानाजनप्रवर्त्तितागमप्रतिकूलधर्ममा-र्गप्रवाहपतितस्य मिथ्यात्वमोहकर्मक्षयोपशमतया समं सम्यक्सन्मार्गमवगम्य जिनशासनानुवा-दद्वारेण यथावस्थितमुक्तिमार्गमुपदिदर्शयिषुर्भविकलोकस्यानुग्रहार्थं सर्वथा सन्मार्गामृतशंशी-त्यनलशमसुधाप्रपातसमम् । संसारमहामहीरुहमूलभूतानाद्यविद्यावासनाबलायातमिथ्यात्व-निर्मूलनसहं शिवमार्गप्रणेतृदेवताविशेषसद्धर्मसन्मार्गसद्गुरुजीवादितत्त्वस्वरूपप्रकाशकं अत्यन्तं करुणापरीतचेताः सुगृहीतनामधेयो भगवान् श्रीचंद्रप्रभसूरिर्दर्शनशुद्धिनामकं शास्त्रं चिकीर्षु-र्मंगलसंबंधाभिधेयप्रयोजनप्रतिपादनप्रतिबद्धमादाविदं गाथाद्वयमाह ॥ छ ॥

पत्तभवन्नवतीरं दुहदवनीरं शिवंबतरुकीरं ।
कंचणगोरसरीरं नमिऊण जिणेसरं वीरं ॥

वोच्छं तुच्छमईणं अणुग्गहत्थं समत्थभव्वाणं ।
सम्मत्तस्स सरूवं संखेवेणं निसामेह ॥

तत्र विघ्नविनायकोपशमनाय श्रोतृजनप्रवृत्त्यर्थं शिष्टसमयपरिपालनार्थं तावदादितो मंगलमुपादेयम् ।

अन्तः—

संप्रति पुनरपि शास्त्रगतोपदेशमाह—

एयं दंसणसोहिं सव्वे भव्वा पढंतु निसुणंतु ।
जाणंतु कुणंतु लहंतु सिवसुहं सासयं झत्ति ॥

अस्या व्याख्या । एतां दर्शनशुद्धिं सर्वेऽपि भव्याः पठंतु सूत्रतो निःश्रृण्वंत्वर्थतः । जानंतु पुनः पुनरभ्यासतः ।

यः कंदर्पतरोः कुठारललितो लीलाजितेभः प्रभु-
र्यस्याशेषसुरासुरेंद्रशिरसा पादद्वयं घृष्यते ।
हेलांदोलितमंदिरो जिनपतिः श्रीवर्द्धमानोऽनघः
तीर्थस्यास्य विभुर्जगत्त्रयनतो जीयाज्जगद्भास्करम् ॥ १ ॥

स्यात्तस्याथ भवाटवीसुगहने नानाकुतीर्थिव्रजो-
त्सर्पत्श्वापदभीतिके कटुरटन्मेहोग्रघूकाकुले ।
नानाजीवमहीतले तवगणोत्सर्पत्कुजौघाकरे
वाव्याव्यादिमहातिदुःखगहनोल्लासिप्रतापेऽधिकम् ॥ २ ॥

शीलोत्तुंगविशालपालिकलितं सच्छ्रावकश्राविका-
नानावृक्षवृतं समस्तसुतपःस्वाध्यायनीराकरम् ।
नानालब्धिरथांगपक्षिनिवहोल्लासिप्रकोलाहलं
प्राणित्रासादतीर्थ(?) चारुसुसरस्तत्त्वोदसद्दर्पणम् ॥ ३ ॥

तस्मिन्नुग्रविशालशीलकलितस्वाध्यायध्यानोद्यतो-
त्सर्पच्चारुतपःसुसंयमयुतश्रेयःसुधा....लयः ।
सच्छीलांगदलः कलंकविकलो ज्ञानादिगंधोद्धुरः
सेव्यो देवनृपद्विरेफसुततेः श्रीचंद्रगच्छोंऽबुजः ॥ ४ ॥

तस्मिंस्तीर्थविभूषकेऽभवदथ श्रीसर्वदेवप्रभुः
सूरिः शीलनिधिर्धिया जितमरुत्सूरिः सतामग्रणीः ।
तस्याऽप्यद्भुतचारुचंचदमलोत्सर्पद्गुणैकास्पदं
स्याच्छिष्यो जयसिंहसूरिरमलस्तस्यापि भूभूषणम् ॥ ५ ॥

हेलानिर्जितवादिवृंदकलिकालाशेषलुप्तव्रता-
चारोत्सार्पितसत्पथैककदिनः सिंहः कुमार्गद्विपे ।

चंचच्चंचलचित्तवृत्तिकरणग्रामाश्वघातो वभू
श्रीचंद्रप्रभसूरिचारुचरितश्चारित्रिणामग्रणीः ॥ ६ ॥

ज्ञानादित्रयरत्नरोहणगिरिः सच्छीलपाथोनिधि-
र्द्धीरो धीधनसाधुसंहतिपतिः श्रीधर्मधूर्धारकः ।
स्यात् सिद्धांतहिरण्यघर्षणकृते पट्टः पटुः शुद्धधीः
शिष्यो गच्छपतिः प्रतापतरणिः श्रीधर्मघोषप्रभुः ॥ ७ ॥

तच्छिष्यविमलगणिना कृतिना भ्रात्राऽनुजेन शास्त्रस्य ।
अस्योच्चैर्वृत्तिरियं विहिता साहाय्यतः सुधिया ॥ ८ ॥

निजशिष्यविजयसेनाभिधगणिविहिता द्विधा य....य्यासु ।
करुणामतिगीतार्था विशोध्य विस्तारयंत्वेनाम् ॥ ९ ॥

श्रीवटपद्रकपत्तनविहितावासेन चतुरशीत्यधिकैः ।
एकादशैः शतैर्गतविक्रमकालात्तथा चैत्रे ॥ १० ॥

वदिपक्षचतुर्दश्यां विहितेयं वृत्तिरमलबोधाय ।
स्यात् स्तुत्यार्जितपुन्यं भव्यासुमतां ममापीह ॥ ११ ॥

या विश्वाशेषवस्तुप्रकटनकरणे भानुतुल्या सुपुंसां
यस्याः संपर्कमात्रादखिलसुखमलं लीलयाऽऽसादयंति ।
यामाराध्यातिमूर्खा अपि जननिवहाः पंडिता विश्ववंद्या
जायंते तां नमामि त्रिभुवनविनुतां भारतीं भावतोऽहम् ॥ १२ ॥

यस्याः प्राप्य प्रसादं जडमतिविभवेनाशु वृत्तिः प्रशस्ये-
द्दक्षा विद्वज्जनानाममलसुमनसां भेददा चित्तवृत्तेः ।
नानाविद्याप्रपंचप्रगुणगुरुगुणाशेषलब्धेः प्रकोशा
जीयाज्जैनी सुशास्त्रप्रथमरुहकृते भारती बीजकल्पा ॥ १३ ॥

यावत् पाथोधयोऽयं सुरगिरिरखिलालोकलोकोदरस्थो
यावद् द्वीपोऽथ जंबूस्त्रिभुवनतिलकः पूर्णचंद्राकृतिश्च ।
यावज्जैनोऽथ धर्मो प्रभवति च शशी भूतलं तावदेनां
भव्याः शृण्वन्तु श्रव्यां विषयविमुखतापादिकां बोधिकां च ॥१४॥ छ॥

No. 173: Darśanaśuddhiprakaraṇa with Commentary—Samyaktva-śuddhiprakaraṇa with Commentary

दर्शनशुद्धिप्रकरणम् सटीकम्—सम्यक्त्वशुद्धिप्रकरणम् सटीकम्

Folios – 264 (?)
Language – Prakrit & Sanskrit
Author – Candraprabhasūri

Size – 30 × 2 inches
Condition – Fair
Age of MS. – c. First half of 15th cent. V.S.

General Remarks – Folio 12, 53, 140, 141, 252, 257, 260 and 262 are missing. Only a piece of folio no. 296 is preserved in the ms. As such the last portion of the ms. is incomplete to a great extent.

आदिः—

॥ नमः श्रीपंचपरमेष्ठिभ्यः ॥

यद्वक्त्रांभोजवाप्याः स्फुटवचनघटीयंत्रवारेण निर्यत्सूरिश्रेणिप्रणाली प्रणयिगुरुगणप्रोच्छल-च्छीकरौघात् । ....शिष्टसमयानुवर्त्तनार्थं च मंगलाभिधेयप्रयोजनाभिधायकं प्रथममेव गाथायुग्ममाहु :—

पत्तभवन्नवतीरं दुहदवनीरं सिवंबतरुकीरं ।

*

No. 174: Darśanaśuddhiprakaraṇa with Commentary

दर्शनशुद्धिप्रकरणम्—सटीकम्

Folios – 205
Language – Prakrit & Sanskrit
Author – Candraprabhasūri
Commentator - Devabhadrācārya

Extent – Granthas 3800
Size – 14·5 × 2·2 inches
Condition – Fair
Age of MS. – c. beginning of 14th cent. V. S.

General Remarks – Folios 91–92 missing. Several folios in the beginning are dilapidated.

आदिः—

नत्वा श्रीवर्द्धमानाय निःसीमज्ञानचक्षुषे ।
जितांतरारिवर्गाय सम्यक् तत्त्वार्थदेशिने ॥ १ ॥

अन्तः—

इति श्रीदेवभद्राचार्यविरचितदर्शनशुद्धिप्रकरणविवरणे पंचमं तत्त्वक्त्वं(?) समर्थितम् ॥ छ ॥ * ॥

दात्ममतितो
बुधासत्तेर्लब्ध्वा किमपि पुनराम्नायवशतः ।
इयं दृब्धा वृत्तिस्तदपि यदसत् किंचिदुदितं
विशोध्यं तत्प्राज्ञैरवि................|| १ ||

आस्ते तुंगो घनाभोगः सुप्रतिष्ठो भुवस्तले ।
आस्थानं द्विजसार्थानां श्रीकोटिकगणद्रुमः || २ ||

तत्रायता घनच्छाया सुमनः ।
विख्याता सदैव फलशालिनी || ३ ||

गोभिः सुधावयस्याभिस्तर्पिताशेषभूतलम् ।
तस्यां सुवृत्तसंशोभि चांद्रं विजयते कुलम् || ४ ||

अर्ह ख्यानगुंजारवैः
श्रोतृस्वांतनिकुंजकल्मषमृगानुत्त्रासयन् सर्वतः ।
प्रोन्मादिप्रतिवादिवारणघटाविक्षोभदक्षोऽभवत्
तत्र श्री....................धानः प्रभुः || ५ ||

तच्छिष्यः समजायताद्भुतनिधिश्चारित्रिणामग्रणीः
शास्त्रस्यास्य विधायकः कुशलधीर्निःशेषशास्त्राध्वनि ।
लुप्त....................कर्त्ता कलौ
श्रीचंद्रप्रभसूरिरित्यभिधया ख्यातः क्षितौ सद्गुरुः || ६ ||

एतत्पट्टधुरंधरः शमनिधिः श्रेष्ठस्तपःशालिनां
प्रह्वश्री ज....................क्रमः ।
अर्हच्छासनवार्द्धिवर्द्धनविधौ ताराधिनाथोऽभवद्
भव्यांभोजवनप्रबोधनरविः श्रीधर्मघोषप्रभुः || ६ ||

आचारेण कु....................पः
स्वामित्वेन गुणज्ञता विदुरता शीलेन दाक्ष्यं श्रिया ।
इत्थं यस्य पुरं कुटंबिन इवाध्यूषुर्गुणाः सुस्थिताः
शिष्यस्तस्य समंतभद्र.................... || ७ ||

शिष्यस्तस्याथ **चंद्रप्रभ**परमगुरोरद्वितीयो द्वितीय-
बन्धुः श्री**धर्मघोषा**भिधमुनिवृषभस्यानुजातोऽभिजातः ।
प्रज्ञाप्राग्भारपश्चात्कृ.....................
....ग्रे गण्यो मुनीनां **विमलगणि**रिति श्लाघ्यनामा बभूव ॥ ८ ॥

सरसा विचारबहुला सच्चक्रानंदहेतुरस्ताघा ।
दर्शनशुद्धेर्वृत्तिः क्ष....................॥ ९ ॥

सूरिः श्री**देवभद्रा**ख्यस्तस्य शिष्योऽस्ति मंदधीः ।
प्रतिष्ठितः स्वयं श्रीमद्**धर्मघोषा**ख्यसूरिभिः ॥ १० ॥

गुरोस्तेन बृहद्वृत्तेरुद्धृत्य कतिचिल्लवान् ।
....................हितकाम्यया ॥ ११ ॥

सूरिश्री**रितिभद्रा**ख्यः (?) स्वशिष्यस्य महामतेः ।
साहाय्यादयमारंभो निष्ठाकोटिमटीकत ॥ १२ ॥

मुनिप्रभानि.................... ।
अलेखि प्रथमादर्शे विश्वविज्ञानशालिना ॥ १३ ॥

ग्रंथाग्रं श्लोकमानेन वृत्तावस्यामुदीरितम् ।
बुधैस्त्रीणि सहस्राणि संयुतान्यष्टभिः शतैः ॥ १४ ॥

............................क्षत्रपुष्पावलीं
चिन्वानः परिवर्त्तते प्रतिदिनं भास्वन्महामालिकः ।
ग्रंथस्तावदयं सुवर्णनिधिवन्नानार्थसिद्धिप्रद-
स्तत्त्वप्रीतितर....कृतधियां चेतश्चिरं चुंबतु ॥ १५ ॥ छ ॥

श्री**पुण्यतिलकसूरीणां** पुस्तिका ॥

*

No. 175 : Dharmaratnaprakaraṇa with Bṛhadvṛtti

धर्मरत्नप्रकरणम्—बृहद्वृत्तिसहितम्

Folios – 279
Language – Prakrit & Sanskrit
Author – Śāntisūri
Commentator – Devendrasūri

Extent – Granthas 9700
Size – 16·7 × 2·7 inches
Condition – Good
Age of MS. – c. First half of 13th cent. V. S.

आदिः—

॥ नमः श्रीप्रवचनाय ॥

सज्ज्ञानलोचनविलोकितसर्वभावनिःसीमंभीमभवकाननदाहदावम् ।
विश्वार्चितं प्रवरभासुरधर्मरत्नरत्नाकरं जिनवरं प्रयतः प्रणौमि ॥ १ ॥

श्रीधर्मरत्नशास्त्रं बह्वर्थं स्वल्पशब्दसंदर्भम् ।
स्वपरोपकारहेतोर्विवृणोमि यथाश्रुतं किंचित् ॥ २ ॥

अन्तः—

इति श्री**धर्मरत्नवृत्तिः समाप्ता** ॥ छ ॥

विष्णोरिव यस्य विभोः पदत्रयी व्यानशे जगन्निखिलम् ।
सद्धर्मरत्नजलधिः स श्री**वीरो** जिनो जयतात् ॥ १ ॥

कुंदोज्ज्वलकीर्तिभरैः सुरभीकृतसकलविष्टपाभोगः ।
शतमखशतविनतपदः श्री**गौतम**गणधरः पातु ॥ २ ॥

तदनु **सुधर्मस्वामी जंबूप्रभवा**दयो मुनिवरिष्ठाः ।
श्रुतजलनिधिपारीणा भूयांसः श्रेयसे संतु ॥ ३ ॥

क्रमश**श्चैत्रावालक**गच्छे कविराजराजिनभसीव ।
श्री**भुवनचंद्रसू**रिर्गुरुरुदियाय प्रवरतेजाः ॥ ४ ॥

तस्य विनेयः प्रशमैकमंदिरं **देवभद्र**गणिपूज्यः ।
शुचिसमयकनकनिकषो बभूव भूविदितभूरिगुणः ॥ ५ ॥

तत्पादपद्मभृंगा निस्संगाश्चंग[........]संवेगाः ।
संजनितशुद्धबोधा जगति **जगच्चन्द्र**सूरिवराः ॥ ६ ॥

तेषामुभौ विनेयौ श्रीमान् **देवेन्द्रसूरि** रित्याद्यः ।
श्री**विजयचंद्र**सूरिर्द्वितीयकोऽद्वैतकीर्तिभरः ॥ ७ ॥

स्वान्ययोरुपकाराय श्रीम**द्देवेंद्रसूरिणा** ।
धर्मरत्नस्य टीकेयं सुखबोधा विनिर्ममे ॥ ८ ॥

प्रथमां प्रतिमप्रतिमां बिभ्राणो गुरुजनेषु भक्तिभरम् ।
विद्वान् विद्यानंदः सानंदमना लिलेखास्याः ॥ ९ ॥

श्रीहेमकलशवाचकपंडितवरधर्मकीर्त्तिमुख्यबुधैः ।
स्वपरसमयैककुशलैस्तदैव संशोधिता चेयम् ॥ १० ॥
यद्गदितमल्पमतिना सिद्धांतविरुद्धमिह किमपि शास्त्रे ।
विद्वद्भिस्तत्त्वज्ञैः प्रसादमाधाय तच्छोध्यम् ॥ ११ ॥
बह्वर्थमल्पशब्दं शास्त्रमिदं रचयता मया कुशलम् ।
यदवापि धर्मरत्नप्राप्तिर्जगतोऽपि तेनास्तु ॥ १२ ॥ छ ॥

ग्रंथाग्रं ९७०० प्रमाणम् ॥ छ ॥

*

No. 176 : Vivekamañjarīprakaraṇa with Commentary

विवेकमञ्जरीप्रकरणम्—सटीकम्

Folios – 242
Language – Prakrit & Sanskrit
Author – Āsaḍa
Commentator – Bālacandrasūri
Date of Composition – V.S. 1248.
Extent – Gāthās 144
Size – 32.7 × 2.5 inches
Condition – Good
Age of MS. – V.S. 1322 (?)

General Remarks – Folio 1 contains a nice illustration of Ṛṣabhadeva, the first *Tīrthaṅkara,* whose favour is invoked in the beginning of the text. Folio 2 contains a nice picture depicting the Ācārya expounding the Vivekamañjarī and one of his pupils as also Āsapāla, who got the ms. copied down, and Āsapāla's wife listening to the sermon. There are three more illustrations on folios 239, 240 and 269.

आदिः—

॥ ॐ ॥ अर्हं ॥ श्रीनाभिनंदनविभोर्वदनं मुदेऽस्तु
श्रीशारदासदनमक्षगवाक्षरम्यम् ।
स्कन्धाचलोपरि कलश्रुतिदोलयोर्य—
त्पर्यंतयोरुपवनीयति कुंतलाली ॥ १ ॥
देवाधिदैवतमतीवमतानि शान्तिः
श्रेयांसि वो दिशतु संहृतविश्वतान्तिः ।
यत्पादयोर्नखरुचः प्रणतेषु शान्ति—
तोयच्छटात्वमरुणच्छवयः प्रयान्ति ॥ २ ॥

मर्यादयाऽपि कलितः प्रियनिम्नगोऽसौ
कुग्राहवानतिगभीरगिरान्वितोऽपि
हित्वा समुद्रमिति कंबुरगाद् यदंकं
स श्रीजिनो वृजिनमस्यतु **शंखलक्ष्मा** ॥ ३ ॥

निर्मेघमेघपथमेचकदेहधामा
वामासुतः स भवताद् भवतां विभूत्यै ।
यन्मौलिसीम्नि रुचि मंडलसप्तसप्तेः
सप्तापि सप्तय इवाहिफणाः स्फुरंति ॥ ४ ॥

ते वः शिवश्रियमपश्चिमतीर्थनाथ-
पादारविन्दनखचंद्रमसो दिशन्तु ।
कामं कलंकविकलाः सकलांकसिंह-
भीप्रोषितोदरमृगा इव ये विभान्ति ॥ ५ ॥

नम्रासुरत्रिदशकोटिकिरीटकोटि-
शाणानिशातपदपद्मनखेन्दुकान्ताः ।
कान्तानि वः शिवसुखानि दिशन्तु शश्व-
दन्येऽपि तीर्थपतयोऽ**जितनाथ**मुख्याः ॥ ६ ॥

मोहांधकारधिक्कारदीपिका मुक्तिवर्त्मनि ।
विवेकमंजरीवृत्तिरियं निर्वर्त्यते मया ॥ ७ ॥ छ ॥

इह हि महितगुणमहिमकुमुदहिमकरस्य मकरकेतुबाणवित्रस्तसमस्तजनपरित्राणवज्रपंजरस्य **गूर्जर**वसुंधरावदन**मंडलीनगर**मण्डनश्री**महावीरचैत्य**प्रतिष्ठाकृतः सुकृतचरितचमत्कृतदेवेन्द्रस्य श्री**देवेन्द्र**गुरुस्वहस्तस्वपदविनिवेशितस्य भुवनभद्रंकरस्य श्री**भद्रेश्वर**सूरिगुरोः पट्टनभस्तलालंकरणकिरणमालिना प्रतिवादिदैत्यदमनसौरिणा श्री**मदभयदेव**सूरिणा समुपदिष्टसकलसिद्धान्तसारः संसारवैराग्यरसप्रसरपुष्टचेताः शिष्टसमयसरसिजवनीविकाशनैकरविः श्रीम**दासडकविः कविसभाशृंगार** इत्यपरनामधेयः श्रेयःप्रवृत्तिसुभगम्भावुकभविकजनचक्रप्रमोदसंपादनच्छेकरुचि**र्विवेकमंजरीप्रकरण**करणमभीष्टदेवतानमस्कारपुरःसरं प्रतिजानीते यथा ॥ **छ** ॥ **ग्रं**. २१ ॥

सिद्धिपुरसत्थवाहं वीरं नमिऊण चरमजिणनाहं ।
सवणसुहारससरियं वुच्छामि **विवेगमंजरियं** ॥ १ ॥

अन्तः—

अथ प्रशस्तिगाथामाह—

सिरि**भिल्लमाल**निम्मलकुलसंभव**कडुयराय**तणएण ।
इय **आसडेण** रइयं वसुजलहिदिणेसवरिसम्मि ॥ १४४ ॥

व्याख्या—

एतद्धि विवेकमंजरीनामधेयं प्रकरणं आसडेन रचितं रचनामानीतम् । किंविशिष्टेन । सिरिभिल्लमाल त्ति । निर्मलं निर्दूषणं च तत् कुलं च निर्मलकुलं, श्रिया उपलक्षितं तत् भिल्लमालाख्यं निर्मलकुलं च, तस्मात् संभवतीति श्रीभिल्लमालकुलसंभवः । स चासौ. **कटुकराज**स्तस्य तनयः पुत्रो यः स तथा तेन । कदेत्याह । वसुजलहिदिणेसवरिसम्भि । वसवोऽष्टौ जलधयश्चत्वारो दिनेशा द्वादश तैर्निर्मितं वर्षं वसुजलधिदिनेशवर्षं तत्रेति संक्षेपार्थः। व्यासार्थस्तूच्यते ॥ छ ॥

श्री**भिल्लमाला**भिधया प्रसिद्धो **वंशो**ऽवतंसो जगतीतलस्य ।
समस्ति पाथोधिरिवाच्युतश्रीसरस्वतीवासनिवास एकः ॥ १ ॥

तस्मिन्नवो रजनिजानिरिवाजनिष्ट
भासा पटुः **कटुकराज** इति प्रतीतः ।
यो जैनदर्शनमयो भवमूर्ध्नि चक्रे
लीलास्पदं पदमखंडितवृत्त एव ॥ २ ॥

सुधांशो रोहिणीवास्य बुधपुत्रप्रसूः प्रिया ।
बभूवाऽ**नलदेवी**ति सतीजनमतल्लिका ॥ ३ ॥

तयोरजनिषातां द्वौ सुता**वासडजासडौ** ।
सत्पथं न व्यलंघेतां धुर्यौ धर्मरथस्य यौ ॥ ४ ॥

आसडः कालिदासस्य यशोदीपमदीपयत् ।
मेघदूतमहाकाव्यटीकास्नेहनिषेचनात् ॥ ५ ॥

श्रुत्वा नवरसोद्गारकिरोऽस्य कवितागिरः ।
राजसभ्याः **कविसभाशृंगार** इति यं जगुः ॥ ६ ॥

जिनस्तोत्र-स्तुतीः पद्य-गद्यबंधैरनेकशः ।
चक्रे यः क्रूरकर्मा हि जांगुलीमंत्रसन्निभाः ॥ ७ ॥

येनोपदेशकंदल्याह्वानप्रकरणच्छलात् ।
कृतं मोक्षाध्वनीनेभ्यः पाथेयातिथ्यमक्षयम् ॥ ८ ॥

आसडस्य मृडस्येव गौरी-गंगे बभूवतुः ।
पृथिवीदेवि-जैतल्लदेव्यौ द्वे तस्य वल्लभे ॥ ९ ॥

जैतल्लदेव्यां तनयावभूतां द्वावेतयो**राजड**नामधेयः ।
ज्येष्ठः कनिष्ठः कलिकालकुंभिद्विड्जैत्रसिंहः किल **जैत्रसिंहः** ॥ १० ॥

अरिसिंह इति **पृथिवीदेव्यां** करपुष्करश्रवद्दानः ।
गुरुगिरिपरिणयकर्मा गज इव कलभोंगजः समभूत् ॥ ११ ॥

पुत्रे **राजड**नाम्नि बालकदलीकांडोपमे स्वःपुरीं
याते **बालसरस्वती**ति विदिते तच्छोकमूढाशयः ।
संबुद्धोऽ**भयदेव**सूरिसुगुरोर्यैरेव वाक्यैरसौ
तैरेवेदमसूत्रयत् प्रकरणं श्री**आसडः** सत्कविः ॥ १२ ॥

एता**मासडि**जैत्रसिंहसचिवेनात्यर्थमभ्यर्थितो
वृत्तिं श्री**हरिभद्र**सूरिसुगुरोः शिष्यप्रशस्यावधिः ।
वाग्देवीप्रतिपन्नसूनुरकृत श्री**बालचंद्रा**ख्यया
विख्यातोऽधिपतिर्गणस्य गणिनी**रत्नश्रियो** धर्मजः ॥ १३ ॥

नागेन्द्रगच्छार्णवपार्वणेन्दुरेतां **बृहद्गच्छ**नभोरविश्च ।
श्रीमान् विपूर्वो **जयसेनसूरिः** श्री**पद्मसूरिः** समशोधयेताम् ॥ १४ ॥

देवानन्दमुनीन्दुगच्छगगनालंकारशीतद्युतेः
शिष्यः श्री**कनकप्रभा**भिधगुरोस्त्रैविद्यचूडामणेः ।
वाग्देवीसुत**बालचन्द्र**सुकवेरासप्रतिष्ठः सुधी-
रेतस्यां सहकारिकारणमभूत् **प्रद्युम्नसूरिः** पुनः ॥ १५ ॥

उत्सूत्रं यदसूत्रि सूत्रविकलेनालक्षणं लक्षण-
न्यूनेन श्लथरीतिरीतिरिपुणा व्यर्थं हतार्थेन च ।
किंचित् क्वापि मया वचः प्रलपितं स्वच्छंदमच्छंदसा
तच्छोध्यं विबुधैः परैरपि परं कृत्वा प्रसादं मयि ॥ १६ ॥

श्रीधातुर्लेखशाली त्रिदशपथमहालेखिनीदंडशाली
सायं सायं किलायं सितकरखटिनीपात्रमादाय कालः ।
यावद् द्यौपट्टिकायामुडुलिपिविपुलं हस्तलेखं विधत्ते
तावद्वावच्यमाना कृतिभिरतितरां वर्त्ततां वृत्तिरेषा ॥ १७ ॥ छ ॥

इत्याचार्य श्री**बालचन्द्र**विरचितायां **विवेकमंजरीवृत्तौ** भावनाविवरणं नाम चतुर्थः परिमलः ॥ छ ॥

उद्दंडशैलमयदंडधृतस्य धात्रीछत्रस्य वारिधिदुकूलवृत्तस्य मौलौ ।
स्वर्णाचलः कलशतामयमेति यावत्तावज्जयं कलयतादिह **जैत्रसिंहः** ॥ १ ॥ छ ॥

समाप्ता चेयं विवेकमञ्जरीप्रकरणवृत्तिः ॥ छ ॥ मंगलं महाश्रीः ॥ छ ॥ भद्रमस्तु ॥ छ ॥ * ॥ छ ॥

॥ ॐ नमः श्रीवीतरागाय ॥

यन्नाममंत्रवशवतोऽपि शरीरभाजां नश्यन्ति सामजघटा इव दुष्कृतौघाः ।
पादाग्रलांछनमृगेन्द्रभुवा भियेव देवः स वः शिवसुखानि तनोतु **वीरः** ॥ १ ॥

विस्तीर्णोऽयं क्षितिरुह इव श्लाघ्यमूलप्रतिष्ठः
प्राग्वाटाख्यो गरिमगुणवानन्वयोऽस्ति प्रधानः ।
लक्ष्मीर्यस्मिन्नवकिसलयश्रेणिशोभां बिभर्त्ति
ज्योत्स्नाकारा विकचकुसुमस्तोमसाम्यं च कीर्त्तिः ॥ २ ॥

आद्यस्तत्रानवद्यश्रीः **सीदः** श्रीद इवाभवत् ।
विश्राणनेन यश्चित्रं तत्याज न कुलीनताम् ॥ ३ ॥

वीरदेव्यभिधया शुभलीला तस्य शीलपरिपालनशीला ।
देहिनीव कमला विमलाऽभूद्देहिनी सुकृतनिर्मलबुद्धेः ॥ ४ ॥

चन्द्र इव **पूर्णदेवः** सुतस्तयोः सुगुणकिरणसंपूर्णः ।
दोषाश्रितो न चित्रं कलंकितां न भजते यस्तु ॥ ५ ।

लोकोपकारकरणाद्विजयाद्यासिंहसूरेरुपास्तिजननाज्जिनबिम्बक्लृप्तेः ।
पुत्रद्वयव्रतविधापनतश्च चक्रे यः सार्थकं द्रविणवायुरपि स्वकीयम् ॥ ६ ॥

तस्य च प्रियतमाऽजनि रम्या **वाल्हिविः** शशिसमुज्ज्वलशीला ।
वीतरागचरणार्चनचित्ता क्षेत्रसप्तकवितीर्णसुवित्ता ॥ ७ ॥

क्लृप्तोपतापनिधनं विधि**नोपधानाभिख्यं तपः** शिवसुखाय विधाय धैर्यात् ।
मालाधिरोपणमकारयदात्मनो या द्वेषद्विषो **विजयसिंहगुरोः** करेण ॥ ८ ॥

त्रपामणिक्षोणिरसावसूत सुतान् दिगीशान् स्फुटमष्टसंख्यान् ।
ये पुण्यकाष्ठाश्रितचेतसोऽपि चित्रं न संक्रंदनयोगमापुः ॥ ९ ॥

भोगिभोगायितभुजस्तंभः कुलगृहं श्रियः ।
आद्यस्तत्राभिरामश्रीः **ब्रह्मदेवो**ऽभवत् सुतः ॥ १० ॥

अभिरामगुणग्रामद्रुमारामवसुंधरा ।
दयिता **पोइणि**स्तस्य बभूव प्रियसंवरा ॥ ११ ॥

वासनावासितस्वान्त**श्चन्द्रावत्यां** महत्तमे ।
यश्चैत्ये कारयामास **बिम्बं वीरजिनेशितुः** ॥ १२ ॥

या **पद्मदेवसूरे**र्गुरोः कृते शुभमतिः स्ववित्तेन ।
चरितं त्रिषष्टिमध्यादलेखयत् प्रथमतीर्थकृतः ॥ १३ ॥

द्वैतीयीको **बोहडि**रभवत्तनुजो गुणव्रजनिकेतम् ।
एतस्या**वीति** कुटुंबिनी च चंचद्गुणकदंबा ॥ १४ ॥

स्वकीयवंशे भुवनावतंसे ध्वजानुकारं दधदंगजन्मा ।
सद्धर्मनिर्मापणदत्तवित्तचित्तस्तयो**र्बिल्हण**संज्ञ आद्यः ॥ १५ ॥

सती सतीसंहतिशीर्षरत्नं तस्य प्रिया जैनपदाब्जभृंगी ।
बभूव दानादिगुणप्रधाना सन्मानसा **रूपिणि**नामधेया ॥ १६ ॥

द्वितीय **आल्हण**श्चाभूद्भाग्यसौभाग्यजन्मभूः ।
अनन्यजनसामान्यसौजन्यमणिरोहणः ॥ १७ ॥

जल्हणस्तृतीयः सूनुश्चतुर्थो **मल्हणा**भिधः ।
समभून्**मोहिनी** चापि सुता स्वजनमोहिनी ॥ १८ ॥

जल्हणस्य तृतीयस्य **नाऊ** जाया शुभाशया ।
वीरपालो वरदेवो वैरिसिंहः सुतास्तयोः ॥ १९ ॥

बहुदेवस्तु तृतीयो यश्चारित्रं च सूरिपदवीं च ।
संप्राप्य नाम लेभे सूरिः श्री**पद्मदेव** इति ॥ २० ॥

चतुर्थ **आमण**श्चारुगुणमाणिक्यमंडितः ।
पंचमो **वरदेवा**ख्यः सत्सख्यविहितोद्यमः ॥ २१ ॥

षष्ठः पंडितसंहतिचतुरः स्फूर्जद्यशा **यशोवीरः** ।
आचार्यपदे लेभे श्री**परमानन्द** इत्यभिधाम् ॥ २२ ॥

सप्तमो **वीरचन्द्रा**ख्यो यतोऽनूनगुणावलिः ।
समभूज्जि**नचंद्रा**ह्वः प्रकृष्टवपुरष्टमः ॥ २३ ॥

बोहडिजा **बिल्हण**स्य च पुत्रचतुष्टयमनूनगुणरूपम् ।
रूपिणिकुक्षिसरोवरकलहंसनिभं विवेकयुतम् ॥ २४ ॥

आसापालः कीर्त्तिवल्ल्यालवालः **सीधू**नामा भूरिधामा द्वितीयः ।
तार्त्तीयीकोऽभूज्ज**गत्सिंह**संज्ञस्तुर्यः सूनुः **पद्मसिंहा**भिधानः ॥ २५ ॥

वीरीति पुत्री सुगुणैः पवित्रा मनोहरा सा हरिणीसुनेत्रा ।
अभूच्छुभाचारपवित्रपात्रा सद्रूपलावण्यविशुद्धगात्रा ॥ २६ ॥

जग्राह यः पुत्र इह तृतीयः कामप्रदां संयमराज्यलक्ष्मीम् ।
क्षिप्रं तथा सूरिपदं च लेभे सुदुर्लभं पुण्यवताऽपि पुंसा ॥ २७ ॥

प्रथमस्याऽऽ**सपाल**स्य **खेतुका**कुक्षिसंभवाः ।
सज्जनोऽभयसिंहाख्यस्ते**जाकः सहजा** सुता ॥ २८ ॥

सीधूकाख्यद्वितीयस्य **सोहगे**त्यभवद्वधूः ।
अगण्यपुण्यदाक्षिण्यलावण्यादिगुणान्विता ॥ २९ ॥

तुर्यस्य **पद्मसिंह**स्य **वाल्हू**नाम्नी प्रियाऽभवत् ।
सुतस्तयोः समुत्पन्नो **नागपाला**भिधः सुधीः ॥ ३० ॥

किंच—

रूपं बलं च विभवो विषयाभिषंगो नीरोगता लवणिमा प्रियसंप्रयोगः ।
वातावधूतपटचञ्चलमेव सर्वं विज्ञाय धर्मनिपुणैर्भविभिर्विभाव्यम् ॥ ३१ ॥

अंगुष्ठमात्रं यो बिम्बं कारयत्यर्हतां बुधः ।
सिद्धिनारीपरिरंभभवं स लभते सुखम् ॥ ३२ ॥

न मनःपर्ययमवधिर्न केवलज्ञानमत्र नैवास्ति ।
पुस्तकलेखनमेतत्तद्यष्टिर्दृष्टिहीनानाम् ॥ ३३ ॥

श्रीरत्नप्रभसूरेर्गुरोः सकाशान्निजस्य सद्बन्धोः
संसाराम्भोधितरीं श्रुत्वेत्यथ देशनां विशदाम् ॥ ३४ ॥

होडापद्रपुरे चैत्ये कारयामास भावभाक् ।
श्रीमतः सुमतेर्बिम्बमर्हतस्त्रिजगत्पतेः ॥ ३५ ॥

अलेखयत् सैष किलाऽऽसपालः श्रेयः श्रिये स्वस्य पितुः प्रधानम् ।
विवेकमञ्जर्यभिधां दधानं सत्पुस्तकं निर्वृतिदीपकल्पम् ॥ ३६ ॥

यावत् पूर्वाद्रिशृंगोदित इह जगति स्वप्रतापेन हन्ति
प्रोद्यन्नीलीविनीलं तिमिरभरमरं तापनस्तत्समन्तात् ।
यावच्छेषाहिराजः क्षितिमलयमसौ स्फूर्तिमान् संबिभर्त्ति
श्रेयोधिष्ठानयानप्रवरर.... निभः पुस्तकस्तावदास्ताम् ॥ ३७ ॥

चक्षुर्लोचनविष्टपात्रिनयनप्रोद्भूतसंवत्सरे (१३३३ ?)
मासे कार्त्तिकनाम्नि चंद्रसहिते कृष्णाष्टमीवासरे ।
वृत्तिर्निर्वृतिमार्गदीपकलिकातुल्या विनीतात्मना
रामेण स्वयमादरेण लिखिता नंद्यादनिन्द्याक्षरा ॥ ३८ ॥ छ ॥

प्रशस्तिः समाप्ता ॥ छ ॥ शुभमस्तु ॥ ॐ ॥ पूज्यश्रीप्रद्युम्नसूरिभिः प्रशस्तिः शोधितेति ॥ छ ॥

*

No. 177 : Upadeśamālāprakaraṇa-Heyopādeyāṭīkā
उपदेशमालाप्रकरण-हेयोपादेयाटीका

Folios – 204
Language – Sanskrit
Author – Siddharṣi
Age of MS. – V. S. 1383.

Extent – Granthas 3500
Size – 19·2 × 2·2 inches
Condition – Good

आदिः—

॥ ॐ ॥ नमः सर्वज्ञाय ॥

हेयोपादेयार्थोपदेशभाभिः प्रबोधितजनाब्जम् ।
जिनवरदिनकरमवदलितकुमततिमिरं नमस्कृत्य ॥ १ ॥

गीर्देवताप्रसादितधाष्टर्यान्मंदतरजंतुबोधाय ।
जडबुद्धिरपि विधास्ये विवरणमुपदेशमालायाः ॥ २ ॥

अभिधेयादिशून्यत्वादस्या विवरणकरणमनर्थकमिति चेन्न, तत्सद्भावात्तथा ह्यस्यामुपदेशा अभिधेयास्तदभिधानद्वारेण सत्त्वानुग्रहः कर्त्तुरनंतरप्रयोजनम् । श्रोतुस्तदधिगमात् । द्वयोरपि परमपदावाप्तिः परंपराफलम् । संबंधस्तूपायोपेयरूपस्तत्रोपेयं प्रकरणार्थपरिज्ञानं प्रकरणमुपायोऽतो युक्तमेतद्विवरणकरणमिति । अत्राद्यगाथया शिष्टसमयानुसरणार्थं भावमंगलमाह ॥ छ ॥ जगचूडामणीत्यादि ॥ छ ॥

अन्तः--

जुग्गा गाहा ॥ छ ॥ योग्योचिता वैराग्यं विद्यते येषां ते वैराग्यकाः सुश्रावका गृह्यन्ते । सुसाधवश्च वैराग्यकास्तेषां परलोकप्रस्थितानां च संयमोन्मुखतया परत्र हिताभ्युद्यतानामित्यर्थः । केषां संविग्नपाक्षिकाणां योग्येति वर्त्तते । दातव्या पुनरियं बहुश्रुतेभ्यश्च विवेकिभ्यः चशब्दाच्च सुसाधुत्वादिविशेषणेभ्य इति । इह च सूत्रे पाठानां बाहुविध्याद्य एव पर्यालोचयतां सम्यगर्थप्रदः प्रतिभातः स एवास्माभिः पाठो विवृतः, न शेषाः । क्वचित् पुनः सान्निहितसूत्रादर्शेषु प्रस्तुतार्थेनाघटमानं पाठमवेक्ष्य प्रायोऽयमेव क्वचित् पाठो भविष्यतीत्यूहितः स इति ।

विषं विनिर्द्धूय कुवासनामयं व्यचीचरद् यः कृपया मदाशये ।
अचिंत्यवीर्येण सुवासनासुधां नतोऽस्मि तस्मै जिनधर्मसूरये ॥ १ ॥

उत्सूत्रमत्र विवृतं मतिमांद्यदोषाद् गांभीर्यभाजि वचने यदनंतकीर्त्तेः ।
संसारसागरमनेन तरीतुकामैस्तत्साधुभिः कृतकृपैर्मयि शोधनीयम् ॥ २ ॥

तोषाद्विधाय विवृतिं गिरिदेवतायाः पुण्यानुबंधि कुशलं यदिमां मयाप्तम् ।
सर्वोऽपि तेन भवतादुपदेशमालाप्रोक्तार्थसाधनपरः खलु जीवलोकः ॥ ३ ॥ छ ॥

उपदेशमालाविवरणं समाप्तम् ॥ छ ॥ भगवद्गीर्देवताया निभमात्रदुर्गस्वामिगुरुशिष्य-सिद्धर्षिचरणरेणोः **सिद्धसाधोः** ॥ छ ॥ ग्रंथाग्रं ३५०० ॥ १३८३ वर्षे कार्त्तिक शुदि १३ शनौ अद्येह श्रीदेवगिरौ साधुराजसीहसुतसाधुतिहुणसिंहेन श्रीमदुपदेशमालालघुवृत्ति-पुस्तिका लिखापिता ॥ छ ॥

याद्दशं पुस्तके दृष्टं ताद्दशं लिखितं मया ।
यदि शुद्धमशुद्धं वा मम दोषो न दीयते ॥ छ ॥ ॐ ॥ मंगलमस्तु । शुभं भवतु ॥ छ ॥

*

No. 178 : Upadeśamālāprakaraṇa-with Heyopādeyāvṛtti

उपदेशमालाप्रकरणम्-हेयोपादेयावृत्तिसहितम्

Folios – 286
Language – Prakrit and Sanskrit
Author – Dharmadāsagaṇi
Commentator – Siddharṣi Ācārya

Extent – Granthas 4328
Size – 13 × 2 inches
Condition – Good
Age of MS. – c. Latter half of 13th cent. V. S.

*

No. 179 : Upadeśamālāprakaraṇa with Prākṛtakathāgarbhitavṛtti

उपदेशमालाप्रकरणम्-प्राकृतकथागर्भितवृत्तिसहितम्

Folios – 322
Language – Prakrit and Sanskrit
Age of MS. – c. Latter half of 13th cent. V. S.

Size – 36·5 × 2·5 inches
Condition – Good

General Remarks – Folio no. 323 containing the concluding portion and the author's *Praśasti* is missing, and someone else has written down these on folio no. 322 but not consistently.

*

No. 180 : Upadeśamālāprakaraṇa-Prākṛtakathāgarbhitavṛtti

उपदेशमालाप्रकरण-प्राकृतकथागर्भितवृत्तिः

Folios – 269
Language – Prakrit & Sanskrit
Age of MS. – V. S. 1291

Size – 32·7 × 2.5 inches
Condition – Good
General Remarks – Folio 126 missing.

आदिः—

॥ ॐ ॥ नमो वीतरागाय ॥

हेयोपादेयार्थोपदेशभाभिः प्रबोधितजनाब्जम् ।
जिनवरदिनकरमवदलितकुमततिमिरं नमस्कृत्य ॥ १ ॥
गीर्देवताप्रसाधितधाष्टर्यान्मंदतरजंतुबोधाय ।
जडबुद्धिरपि विधास्ये विवरणमुपदेशमालायाः ॥ २ ॥

अभिधेयादिशून्यत्वादस्या विवरणकरणमनर्थकमिति चेन्न । तत्सद्भावात्तथा ह्यस्यामुपदेशा अभिधेयाः, तद्दानद्वारेण सत्त्वानुग्रहः कर्तुरनंतरप्रयोजनम् । श्रोतुस्तदधिगमो । द्वयोरपि परमपदावाप्तिः परंपराफलं । संबंधस्तूपायोपेयरूपस्तत्रोपेयं प्रकरणार्थपरिज्ञानं । प्रकरणमुपायोऽतो युक्तमेतद्विवरणमिति । तत्राद्यगाथया शिष्टसमयानुपालनार्थं भावमंगलमाह ॥ छ ॥ जग-

चूडामणिगाहा ॥ छ ॥ इयं हि भगवद्गुणोत्कीर्त्तनार्था । तस्य च निर्जराहेतुतया तपोवन्मंगलता स्फुटैवेति ।

अन्तः—

विषं विनिर्द्धूय कुवासनामयं व्यचीचरद्यः कृपया मदाशये ।
अचिंत्यवीर्येण सुवासनासुधां नतोऽस्मि तस्मै **हरिभद्रसूरये** ॥ १ ॥

उत्सूत्रमत्र विवृतं मतिमांद्यदोषाद्गांभीर्यभाजि वचने यदनंतकीर्त्तेः ।
संसारसागरमनेन तरीतुकामैस्तत्साधुभिः कृतकृपैर्मयि शोधनीयम् ॥ २ ॥

तोषाद्विधाय विवृतिं **गिरिदेवतायाः** पुण्यानुबंधि कुशलं यदिमां मयाप्तम् ।
सर्वेऽपि तेन भवता**दुपदेशमाला**प्रोक्तार्थसाधनपरः खलु जीवलोकः ॥ ३ ॥

उपदेशमालाविवरणं समाप्तम् ॥ छ ॥ कृतिरियं जिनजैमिनिकणभुक्सौगतादिदर्शनवेदिनः सकलग्रंथार्थविन्निपुणस्य श्री**सिद्धर्षेर्महावर्द्धमानाचार्य**स्येति ।

सिद्धर्षिकृता विवृतिः कथानकैर्योजिता स्वबोधार्थम् ।
प्राक्तनमुनीन्द्ररचितैश्चारुभिरुपदेशमालायाः ॥

यदविधिनासूत्रोक्तं यच्चन्योक्तं सम्यगिह लिखितम् ।
ौनेन्द्रमताभिज्ञैस्तच्छोध्यं मर्षणीयं च ।
यदत्र मात्राक्षरबिंदुकानां किंचिद्भवेदूनमथाधिकं वा ।
सर्वं तदार्यैर्मम मर्षणीयं क्षमाप्रधाना हि भवंति संतः ॥ छ ॥

ठक्कुर**जैत्रसिंह**स्य.....................**प्रदीपसिंहेन** निपुणेनार्पितां लिपिं ॥छ॥

संवत् १२९१ वर्षे आषाढ शुदि १३ शनौ **उपदेशमालीयपुस्तकं** लिखितमिति ॥छ॥ मंगलं महाश्रीः ॥ छ ॥

श्रीमत्यर्बुदतुंगशैलशिखरच्छायाप्रतिष्ठास्पदे
धर्माणाभिधसन्निवेशविषये न्यग्रोधवृक्षो बभौ ।
यत्शाखाशतसंख्यपत्रबहलच्छायास्वपायाहतं
सौख्येनोषितसंघमुख्यशकटश्रेणीशतीपंचकम् ॥ १ ॥

लग्ने क्वापि समस्तकार्यजनके सप्तग्रहालोकने
ज्ञात्वा ज्ञानवशाद् गुरुं............**देवाभिधः** ।

आचार्यान् रचयांचकार चतुरस्तस्मात् प्रवृद्धो बभौ
वंद्रोऽयं **वटगच्छनाम** रुचिरो जीयाद् युगानां शतीम् ॥ २ ॥

तत्रैकादशसूरिराजविपुले गच्छे प्रतिष्ठाधिकः
पूर्वं श्री**जिनचंद्र**सूरिरभवत् सीमंधरद्योतकः ।
शुद्धात्मा **धवलक्कके** पुरिवरेण्ये **ढाकचैत्या**न्तरे
श्रीसंघप्रभवप्रभावविपुल[प्रद्योत]नद्योतिनि ॥ ३ ॥

तस्मिन् पट्टमहोदधौ नवविधुः श्रीआम्रदेवाभिधः
[श्रीआख्यानक]कोशशास्त्ररचनाचंचन्मतिद्योतिमान् ।
यद्व्याख्यानरसायनामृतमहालाभादहो देवता
कौष्मांडी समुपागमत् प्रमुदिता जीयात् स सूरिप्रभुः ॥ ४ ॥

...............यादिसूरिरभवत् श्रीनेमिचंद्राभिधो
............धर्म्यजिनद्वयीसु चरितप्रख्यातकीर्त्तिस्ततः ।
तार्त्तीयो मुनिपुंगवः समजनि श्रीमान् यशोदेवयुक्
सूरिः सच्चरितप्रसिद्धमहिमा संशुद्धधामा शशी ॥ ५ ॥

पीयूषोन्मुखमुख्यशांतरसवत्सांद्रे मनःस्थानके
सम्यक्कुलक्षणमूल............साहित्यग........बुधिः ।
...............सूरिभिर्वल्लीव वागीश्वरी
यज्ञे........त्तनिश्चयफला............सूरिप्रभोः ॥ ६ ॥

....

*

No. 181 : Upadeśamālāprakaraṇa-Doghaṭṭīvṛtti

उपदेशमालाप्रकरण-दोघट्टीवृत्तिः

Folios – 311
Language – Sanskrit, Prakrit, Apabhraṃśa
Author – Ratnaprabhasūri, disciple of Vādidevasūri

Size – 35 × 2·2 inches
Condition – Good
Composition – V. S. 1238
Age of MS. – c. First half of 14th cent. V. S.

आदिः—

॥ ॐ ॥ नमः श्री**देवसूरि**गुरुपादुकाभ्यः ॥

यस्यारघट्टस्य घनोपदेशमालार्पितध्यानघटाघटीभिः ।
संसारकूपाद् भवभृज्जलानामूर्ध्वं गतिः स्यात् स जिनोऽवताद् वः ॥

रागादिक्षपणपटुः स केवलश्री-
जृम्भारित्रजमहितो यथार्थवाक्यः ।
नाभेयः स भवतु भूतये सदा न-
स्तीर्थस्याधिपतिरयं च **वर्धमानः** ॥

पायं पायं प्रवचनसुधां प्रीयते या प्रकामं
स्वैरं स्वैरं चरति कृतिनां कीर्त्तिवल्लीवनेषु ।
दोग्ध्री कामान् नवनवरसैः सा भृशं प्रीणयन्ती
मादृग्वत्सान् जयति जगति श्रीगवी **देवसूरेः** ॥

विशुद्धसिद्धान्तधुरां दधानां संसारनिस्सारकृतावधानाम् ।
श्राद्धः सुधासिन्धुमिमां विशालां प्राप्नोति पुण्यै**रुपदेशमालाम्** ॥

सत्यामपि सद्वृत्तौ वृत्तिममुष्याः करोम्यहृदयोऽपि ।
त्वरयति यस्मान्मामिह सविशेषकथार्थिनां यत्नः ॥

तत्रादौ मंगलाभिधेयादि प्रतिपादनायाह ॥ नमिऊण गाहा । अत्र पूर्वार्धेन निर्विघ्न-**मारब्धप्रकरणसमाप्त्यर्थमिष्टदेवतानमस्काररूपं** मंगलमपरार्द्धेन पुनरध्येतृश्रोतृव्याख्यातृ-**प्रवृत्त्यर्थमभिधेयसम्बन्धौ** साक्षादाह ।

अन्तः—

इति श्री**रत्नप्रभसूरि**विरचितायामु**पदेशमालाविशेषवृत्तौ** चतुर्थो विश्रामः ॥ छ ॥ ॥ * ॥ छ ॥

नानारूपनरोत्तमैकवसतिर्नीरागतासंगतः
पातालं परितः स्फुरन्निह **बृहद्गच्छो**ऽस्ति रत्नाकरः ।
स श्रीमन्**मुनिचन्द्रसूरि**सुगुरुस्तत्राभवद् भूरिभिः
शाखाभिर्भुवि यः **प्रयागवट**वद् विस्तारमुद्रामगात् ॥

साहित्यतर्कागमलक्षणेषु यद्ग्रंथवीथी कविकामधेनुः ।
कस्योपकारं न चकार सम्यग् निःशेषदेशेषु च यद्विहारः ॥

शिष्यः श्री**मुनिचन्द्र**सूरिगुरुभिर्गीतार्थचूडामणिः
पट्टे स्वे विनिवेशितस्तदनु स श्री**देवसूरि**प्रभुः ।
आस्थाने **जयसिंहदेव**नृपतेर्येनास्त**दिग्वाससा**
स्त्रीनिर्वाणसमर्थनेन विजयस्तम्भः समुत्तम्भितः ॥
तत्पट्टप्रभवोऽभवन्नथ गुणग्रामाभिरामोदयाः
श्री**भद्रेश्वर**सूरयः शुचिधियस्तन्मानसप्रीतये ।
श्री**रत्नप्रभ**सूरिभिः शुभकृते श्री**देवसूरि**प्रभोः
शिष्यैः सेयमकारि सम्मदकृते वृत्तिर्विशेषार्थिनाम् ॥
श्री**देवसूरि**शिष्यभ्रातॄणां **विजयसेन**सूरीणाम् ।
आदेशस्यानृणभावमगममेतावताऽहमिह ॥
यदियम्**उपदेशमाला श्रावकलोकस्य मूलसिद्धान्तः ।**
प्रायेण पठति चायं तदिहास्माभिः कृतो यत्नः ॥
व्याख्यातृचूडामणिसिद्धनाम्नः प्रायेण गाथार्थ इहाभ्यधायि ।
क्वचित् क्वचिद् या तु विशेषरेषा सद्भिः स्वयं सा परिभावनीया ॥
यदिह किंचिदनागमिकं क्वचिद् विरचितं मतिमन्दतया मया ।
तदखिलं सुधियः क्षमयामि च कृतकृपाः परिशोधयतादरात् ॥
स्वस्य परस्य च सूक्तैर्वृत्तिर्विस्तारिता चकास्तीयम् ।
मणिखण्डमण्डलैरिव सुवर्णपूजा जिनेन्द्राणाम् ॥
प्रकृता समर्थिता च श्री**वीरजिना**ग्रतो **भृगुपुरे**ऽसौ ।
अश्वावबोधतीर्थे श्री**सुव्रत**पर्युपास्तिवशात् ॥
संशोधिता च सन्निहितकतिपयैः सहृदयैरियं प्रायः ।
पुनरपि कण्टकशुद्धिः कार्या वः प्रार्थये सर्वान् ॥
भास्वद्भास्वरकान्तकान्ततिलकं प्रक्षिप्तवज्राकृतं
निर्यन्नीलशिलातलांशुपटलीदुर्वारदुर्वांकुरम् ।
यावन्मेरुमहीभृतं प्रति करोत्यारात्रिकोत्तारणं
ताराभिर्द्युविलासिनी विजयतां तावन्नवैषा कृतिः ॥

विक्रमाद्वसुलोकार्कवर्षे[१२३८]माघे समर्थिता ।
एकादश सहस्राणि मानं सार्द्धशतं तथा ॥ ११९५० ॥
छ ॥ शुभमस्तु ॥ लेखकपाठकयोः ॥ छ ॥ छ ॥
ॐ ॥ नमः श्रीवर्द्धमानाय वर्द्धमानाय वेदसा ।
वेदसारं परब्रह्मब्रह्मबद्धस्थितिश्च यः ॥ १ ॥
स्वबीजमुप्तं कृतिभिः कृषीवलैः इत्यादि

*

No. 182: Bhavabhāvanāprakaraṇa with the author's own commentary

भवभावनाप्रकरणम्-स्वोपज्ञवृत्तिसहितम्

Folios – 325
Language – Prakrit & Sanskrit
Author & Commentator – Maladhārī Hemacandrasūri
Age of MS. – V. S. 1249.

Extent – Granthas 12950
Size – 28·7 × 2·5 inches
Condition – Good
Date of Composition – V. S. 1170

आदिः—

॥ ॐ ॥ नमः सर्वज्ञाय ॥

येनादौ नयसंपदः प्रकटिताः सृष्टा स्थितिर्भूभृता-
मुत्क्षिप्तोऽतिगुरुः स संयमभरस्तप्तं तदुग्रं तपः ।
तस्माज्ज्योतिरवाप्य केवलमयं येनाभिवीक्ष्योद्धृतं
त्रैलोक्यं भवसागरात् तमनघं नौम्याद्यतीर्थंकरम् ॥ १........
वयमपि किल शास्त्रकृतां मध्ये येषां प्रसादलेशेन ।
संजाताः स्वगुरूणां तेषां पदपंकजं वन्दे ॥ ५ ॥

अन्तः—

तत्र प्रत्यक्षरगणनया ग्रंथाग्रं १२९५० ॥ छ ॥ मंगलं महाश्रीः ॥ शुभं भवतु लेखकपाठकयोः ॥ छ ॥ संवत् १२४९ श्रावण वदि ८ सोमे ॥ छ ॥

*

No. 183: Puṣpamālāprakaraṇa with the author's own Vṛtti

पुष्पमालाप्रकरणम्-स्वोपज्ञवृत्तिसहितम्

Folios – 413 सो ल्ह ३
Language – Prakrit & Sanskrit

Extent – Granthas 13968
Size – 30·5 × 1·7 inches

Author – Maladhārī Hemacandrasūri Condition – Fair
Age of MS. – c. latter half of 15th cent. V. S.
General Remarks – A corrected copy. Letters are eradicated at many places probably on account of unsuitable ink. Folios 382-383 missing.

अन्तः—

॥ इति श्रीहेमचन्द्रसूरिविरचितोपदेशमाला समाप्ता ॥ छ ॥

श्रीप्रश्नवाहनकुलांबुनिधिप्रसूतः क्षोणीतलप्रथितकीर्त्तिरुदीर्णशाखः । इत्यादि

....

निजशिष्यलवश्रीहेमचन्द्रसूरिभि........वृत्तिरियम् ।
सूत्रयुता तैरेव हि विहिता श्रुतदेवतावचनात् ॥ ९० ॥

एवं प्रत्यक्षरगणनया सर्वग्रंथाग्रस्य जातानि त्रयोदश सहस्राणि अष्टषष्ट्यधिकानि नव शतानि च ॥ अंकतोऽपि १३९६८ एवं ग्रन्थाग्रम् ॥ छ ॥ पुष्पमालाग्रंथसाग्रंतसमग्राः समाप्ताः ॥ छ ॥

*

No. 184 : Puṣpamālāprakaraṇa with the author's own commentary

पुष्पमालाप्रकरणम्-स्वोपज्ञटीकासहितम्

Folios – 391 Extent – Granthas 14000
Language – Prakrit & Sanskrit Size – 33·2 × 2 inches
Author – Maladhārī Hemacandrācārya Condition – Fair
Age of MS. – c. Latter half of 14th cent. V. S.
General Remarks – This work, having been broken down, is completed probably about the latter half of the 15th century. Many folios in the middle of the ms. are broken to pieces.

आदिः—

॥ ॐ ॥ नमो वीतरागाय ॥

येन प्रबोधपरिनिर्मितवाग्वरत्रां क्षिप्त्वोद्धृतानि भुवनानि भवांधकूपात् ।
निःशेषनाकिविभुवंदितपादपद्मो भूयान्ममाशुभभिदे स युगादिदेवः ॥ १ ॥

अन्तः—

अथ श्रुतबहुमानार्थं शिष्यप्रशिष्यपरंपरा[यां]प्रकरणस्य स्थैर्यार्थं चापश्चिममंगलमाह—
जाव जिणसासणमिणं जाव य धम्मो जयंमि विप्फुरइ ।

ताव पढिज्जउ एसा भव्वेहिं सया सुहत्थीहिं ॥

सुगमा ॥ छ ॥ इति **श्रीहेमचंद्रसूरिविरचितोपदेशमाला समाप्ता** ॥ छ ॥ ग्रंथाग्रं १४००० ॥ छ ॥ शुभमस्तु ॥ छ ॥

*

No. 185 : Upamitabhavaprapañcā Kathā **उपमितभवप्रपञ्चा कथा**

Folios – 393 | Size – 30·5 × 2·5 inches
Language – Sanskrit | Condition – Good
Author – Siddharṣi | Composition – V. S. 962
Age of MS. – c. First half of the 13th cent. V. S.
General Remarks – Folios 391 and 392 contain very nice picture-decorations.

आदिः—

ॐ नमः सिद्धेभ्यः

नमो निर्नाशिताशेषमहामोहहिमार्त्तये ।
लोकालोकामलालोकभास्वते परमात्मने ॥

नमो विशुद्धधर्माय स्वरूपपरिपूर्त्तये ।
मनोविकारविस्तारगोचरातीतमूर्त्तये ॥

नमो भुवनसंतापिरागकेसरिदारिणे ।
प्रशमामृततृप्ताय **नाभेयाय** महात्मने ॥

नमो द्वेषगजेन्द्रारिकुंभनिर्भेदकारिणे ।
अजितादिजिनस्तोमसिंहाय विमलात्मने ॥

नमो दलितदोषाय मिथ्यादर्शनसूदिने ।
मकरध्वजनाशाय **वीराय** विगतद्विषे ॥

अथवा—

अंतरंगं महासैन्यं समस्तजनतापकम् ।
दलितं लीलया येन केनचित्तं नमाम्यहम् ॥

समस्तवस्तुविस्तारविचारापारगोचरम् ।
वचो जैनश्वरं वंदे सूदिताखिलकल्मषम् ॥

मुखेंदोरंशुभिर्व्यासं या बिभर्त्ति विकस्वरम् ।
करे पद्ममचिन्त्येन धाम्ना तां नौमि देवताम् ॥

परोपदेशप्रवणो मादृशोऽपि प्रजायते ।
यत्प्रभावान्नमस्तेभ्यः सद्गुरुभ्यो विशेषतः ॥

इत्थं कृतनमस्कारः शांतविघ्नविनायकः ।
विवक्षितार्थप्रस्तावं रचयिष्ये निराकुलः ॥

अन्तः—

तदिदमत्र सुगुह्यमहो जनाः ! हृदि विधत्त परं परमाक्षरम् ।
मलविशोधनमेव सुमेधसा लघुविधेयमिहाऽऽप्य जिनागमम् ॥

एतन्निःशेषमत्र प्रकटितमखिलैर्युक्तिगर्भैर्वचोभिः
प्रस्तावे भावसारं तदखिलमधुना शुद्धबुद्ध्या विचिंत्य ।
भो भव्याः ! भाति चित्ते यदि हितमनघं चेदमुच्चैस्तरां व-
स्तत्तूर्णं मेऽनुरोधाद्विदितफलमलं स्वार्थसिद्ध्यै कुरुध्वम् ॥

उत्सूत्रमत्र रचितं मतिमांद्यभाजा किंचिद्यदीदृशि मयाऽत्र कथानिबंधे ।
संसारसागरमनेन तरीतुकामे तत्साधुभिः कृतकृपैर्मयि शोधनीयम् ॥

पार्श्विल्लसाधोरपि लिखितं तथा **इत्युपमितभवप्रपंचायां कथायां** पूर्वसूचितमीलकवर्ण्णनोऽष्टमः प्रस्तावः समाप्तः ॥ छ ॥ * ॥ समाप्ता चेय**मुपमितभवप्रपंचा कथे**ति ॥ छ ॥

द्योतिताखिलभावार्थः सद्भव्याब्जप्रबोधकः ।
सूराचार्योऽभवद्दीप्रः साक्षादिव दिवाकरः ॥

स **निर्वृत**कुलोद्भूतो **लाटदेश**विभूषणः ।
आचारपंचकोट्युक्तः प्रसिद्धो जगतीतले ॥

अभूद् भूतहितो धीरस्ततो **देल्लमहत्तरः** ।
ज्योतिर्निमित्तशास्त्रज्ञः प्रसिद्धादेशविस्तरः ॥

ततोऽभूदुल्लसत्कीर्त्ति**र्ब्रह्म**गोत्रविभूषणः ।
दुर्गस्वामी महाभागः प्रख्यातः पृथिवीतले ॥

प्रव्रज्यां गृह्णता येन गृहं सद्धनपूरितम् ।
हित्वा सद्धर्ममाहात्म्यं क्रिययैव प्रकाशितम् ॥

यस्य तच्चरितं वीक्ष्य शशांककरनिर्मलम् ।
बुद्धास्तत्प्रत्ययादेव भूयांसो जंतवस्तदा ॥

सद्दीक्षादायकं तस्य स्वस्य चाहं गुरूत्तमम् ।
नमस्यामि महाभागं **गर्गर्षिं** मुनिपुंगवम् ॥

क्लिष्टेऽपि दुःषमाकाले यः पूर्वमुनिचर्यया ।
विजहारेह निःसंगो **दुर्गस्वामी** धरातले ॥

सद्देशनांशुभिर्लोके द्योतित्वा भास्करोपमः ।
श्रीभिल्लमाले यो धीरो गतोऽस्तं सद्विधानतः ॥

तस्मादतुलोपशमः **सद्दर्षि**(?)रभूदनाविलमनस्कः ।
परहितनिरतैकमतिः सिद्धांतनिधिर्महाभागः ॥

विषमभवगर्त्तनिपतितजंतुशतालंबदानदुर्ललितः ।
दलिताखिलदोषकुलोऽपि सततकरुणापरीतमनाः ॥

यः संग्रहकरणरतः सदुपग्रहनिरतबुद्धिरनवरतम् ।
आत्मन्यतुलगुणगणैर्गणधरबुद्धिं विधापयति ॥

बहुविधमपि यस्य मनो निरीक्ष्य कुंदेंदुविशदमद्यतनाः ।
मन्यंते विमलधियः सुसाधुगुणवर्ण्णनं सत्यम् ॥

उपमितप्रभवप्रपंचा कथेति तच्चरणरेणुकल्पेन ।
गीर्देवतया विहिताऽभिहिता **सिद्धा**भिधानेन ॥

अथवा—

आचार्य **हरिभद्रो** मे धर्मबोधकरो गुरुः ।
प्रस्तावे भावतो हंत स एवाद्ये निवेदितः ॥

विषं विनिर्धूय कुवासनामयं व्यचीचरद्यः कृपया मदाशये ।
अचिंत्यवीर्येण सुवासनासुधान्नतोऽस्मि तस्मै **हरिभद्रसूरये** ॥

अनागतं परिज्ञाय **चैत्यवंदन**संश्रया ।
मदर्थेन कृता येन **वृत्तिर्ललितविस्तरा** ॥

यत्रातुलरथयात्राधिकमिदमिति लब्धवरजयपताकम् ।
निखिलसुरभुवनमध्ये सततप्रमदं जिनेन्द्रगृहम् ॥

यत्रार्थाष्टंकशालायां धर्मः सद्देवधामसु ।
कामो लीलावतीलोके सदाऽऽस्ते त्रिगुणो मुदा ॥

तत्रेयं तेन कथा कविना निःशेषगुणगणाधारे ।
श्री**भिल्लमाल**नगरे गदिता जिनमंडपस्थेन ॥
प्रथमादर्शे लिखिता साध्व्या श्रुतदेवतानुकारिण्या ।
दुर्गस्वामिगुरूणां शिष्यिकयेयं **गणा**भिधया ॥
सम्वत्सरशतनवके द्विषष्टिसहितेऽतिलंघिते चास्याः ।
ज्येष्ठे सितपंचम्यां पुनर्वसौ गुरुदिने समाप्तिरभूत् ॥ छ ॥

मंगलं महाश्रीः ॥ छ ॥ शुभं भवतु लेखकपाठकयोः ॥ छ ॥

श्रीमालाचलमौलिमूलमिलितस्त्रैलोक्यसुश्लाघितः
पर्वालीकलितः सुवर्ण्णनिलयः प्रासादलब्धालयः ।
लीनालीभ्यकुलः प्रलीनकलुषः शुभ्रातपत्रानुगो
वंशोऽस्ति प्रकटः सदौषधनिधिः श्रीध**र्कटानां** पट्टः ॥ १ ॥

सारासारविचारचारुचतुरः सारार्थबद्धादरः
संसारोदरवर्त्तिजंतुशरणश्रीमज्जिनार्चापरः ।
कारुण्याकरसद्गुरुस्तुतिवशप्राप्तार्थदानोद्यत-
स्तत्रात्मीयकुलक्रमोचितरतः स**न्नेमिचन्द्रो**ऽभवत् ॥ २ ॥

तस्यानघा घनपयोधरयुग्मरम्या रामानुरूपगुणरंजितभर्तृचित्ता ।
चिंताव्यतीतफलदायकधर्मलीना **निर्वाणि**नामविदिता जनतासु पत्नी ॥ ३ ॥

जीवाजीवपदार्थसार्थवचनः संपूर्णचंद्राननः
सर्वाधीनधनः सलीलगमनः क्रोधेभपंचाननः ।
नैपुण्यार्जितसज्जनः प्रतिदिनप्रारब्धदानावनः
सूनुः श्लाघितस**र्वदेव**भुवनख्याताभिधानस्तयोः ॥ ४ ॥

देवेन केनापि कदाचिदेष नीतो रजन्यां स्वगृहात् प्रसुप्तः ।
अष्टापदे वंदितवान् जिनेन्द्रान् प्रातः स्वहस्ते कुसुमं ददर्श ॥ ५ ॥

सदा दानासक्ता स्वकुलविमलाचारनिरता सुशीलप्रख्याता पराहितरता दैन्यरहिता ।
अमानातिक्रांता गुणगणयुता सज्जनमता स**द्च्छुप्ता**नामा वरसहचरी तस्य च तयोः ॥ ६ ॥

लक्ष्मीपतिः सुतनयोऽजनि **यक्षदेवः श्रीराजिनि**नयनसम्मद **आम्रदेवः** ।
धाधिनोभवनदीपक**चांदिगा**ख्यस्तुर्यो **यशोमतिवधूप्रियपुंडरीकः** ॥ ७ ॥
चतुर्भिरेभिर्जिनधर्मलीनैर्विभावितागाधभवाब्धिभावैः ।
व्यधायि **धंधाणक**सन्निवेशे शरण्य**चंद्रप्रभदेवहर्म्यम्** ॥ ८ ॥
प्रत्याख्यानं येन कृत्वौदनादेः पद्भ्यां निर्गत्योज्जयंते नगेन्द्रे ।
श्रीमन्नेमिर्वंदितः पूजितश्च क्षिप्रं भूयाद्यक्षदेवः स सौख्यी ॥ ९ ॥
यक्षदेवस्य तस्योद्यमी जातवान् चारुपुत्रः प्रियः **शांतनामा**दिमः ।
धर्मकर्मा सुशीलाऽऽ**म्रदत्ता**भिधः क्रोधकोपाजितः कामरूपोऽर्जितः ॥ १० ॥
धर्मार्थादिचतुःप्रकारपुरुषस्वार्थोद्यतस्यान्यदा
द्वौ द्वौ सुंदरभार्ययोर्वरसुतौ श्राद्धाऽऽ**म्रदेवस्य** तौ ।
संजातौ कुलज**श्रियः** सुसरलौ **पार्श्वाख्यमूणागकौ**
राजिन्या बुधलक्ष्मणो गुणनिधिर्**नागेन्द्र**नामाऽनघः ॥ ११ ॥
सन्नेमिचन्द्रगुणमंदिरदेवचंद्रसूनुद्वयं व्यजनि **चांदिग**नामधेयः ।
प्रद्युम्न-शंबकृतनामकमुज्ज्वलांगं सत्**पुंडरीक**सुधियाऽजनि पुत्रयुग्मम् ॥ १२ ॥
नागेंद्रः शुभधर्मकर्मनिरतः सन्**मोहिनी**भार्यया
पद्मावत्यभिधानया सरलया स्वस्त्रीयया संयुतः ।
चाहिन्या सुतया सुतेन गुणिना **सुश्रीकुमारेण** वै
शांतापत्ययशःप्रियानघ**यशोदेवे**न धर्मार्थिना ॥ १३ ॥
अथान्यदा दानतपोविधानसुभावनाशीलसनाथधर्मे ।
जिनप्रणीते विदधन् प्रयत्नं श्रृणोति धर्म्यं वचनं गुरुभ्यः ॥ १४ ॥

तद्यथा—

निरवधिभववार्द्धौ कर्मदोषाद् भ्रमंतः प्रवरशरणहीना योनिलक्षेषु जीवाः ।
कथमपि त्रुटियोगान्मानुषं जन्मरत्नं सकलगुणविशिष्टं कष्टलक्षैर्लभंते ॥ १५ ॥
प्राप्य तत्प्राणिभिः प्रार्थितार्थप्रदं प्रेरणाप्रोद्यतप्रांजलप्रेरितैः ।
प्रत्यहश्चिंतयित्वा धनाद्यस्थिरं कर्तुमेवोचितं चारु जैनं वचः ॥ १६ ॥
प्राणातिपातविरतिप्रमुखानि यानि जैनागमे निगदितानि महाव्रतानि ।
तानि क्षमा यदि न कर्तुमशक्तियोगाद्यूयं कुरुध्वममलं गृहिधर्ममेनम् ॥ १७ ॥

कर्त्तव्यं जिनपुंगवस्य महनं स्तोत्रैश्च तत्संस्तवः
सेव्यः साधुजनः प्रसन्नवदनैः श्रव्यं जिनेंद्रोदितम् ।
चिंत्या द्वादश भावना निजहिते कार्यः प्रयत्नो महान्
शक्त्या चान्यहिते भवाब्धितरणप्रत्युद्यतैः प्राणिभिः ॥ १८ ॥

मोहादिद्विपकुंभभेदनविधौ येषां सदा पौरुषं
कामित्वं कमनीयमुक्तिललनापीनस्तनस्पर्शने ।
न्यायोपात्तधनं गतं जिनमतक्षेत्रेषु सप्तस्वहो
तेषां पौरुषकामिता विभविता मन्ये कृतार्था भुवि ॥ १९ ॥

रम्ये श्रीजिनपुंगवस्य सदने बिंबे तदीयेऽनघे
संघे श्लाघ्यतमे प्रशस्तचरिते पूज्ये चतुर्वर्णके ।
सर्वज्ञागमलेखने विनिहितं चित्तं भवेदिष्टदं
सत्क्षेत्रे विधिनोप्तमिष्टसमये शाल्यादिबीजं यथा ॥ २० ॥

ये कृत्वा जिनमंदिराणि विधिना संपूज्य वस्त्रादिभिः
श्रीसंघं समुपात्तनीतिविभवाः श्रद्धापराः श्रावकाः ।
स्याद्वादप्रतिबद्धवाक्यजनकश्रीवीररागेण यद्
निर्नीतं किल लेखयंति भविनः किं किं न तैः सत्कृतम् ॥ २१ ॥

श्रुत्वा पुस्तकवाचनामनुदिनं गृह्णन्ति केचिद् व्रतं
देवाधीशजिनेंद्रपूजनपराः श्राद्धा भवेयुः परे ।
अन्ये भद्रकभावभावितमनःसद्धर्मयोग्या नरा
जायंते खलु यस्य पुस्तकमिदं हेतुः स तच्छ्रेयसः ॥ २२ ॥

इत्याकर्ण्य जिनप्रणीतमनघं धर्मं गुरुभ्यस्ततः
पर्यालोच्य कुटुंबकेन गुणिना नागेन्द्रनामा गृही ।
सिद्धाख्येन कृतां कथामुपमितिं सिद्धांतसारोद्धृतां
तोषादेव सुधीर्व्यलीलिखदिमां स्वश्रेयसे पुस्तके ॥ २३ ॥

यावन्मेरुः प्रतपति रविर्द्योतते यावदिन्दु-
र्यावद्वायुः स्फुरति गगने तारकाः संति यावत् ।

यावद्भूमिः प्रवहति पयःसागरे यावदेतत्

तावन्नंद्यागुणिभिरंनिशं पुस्तकं वाच्यमानम् ॥ २४ ॥

॥ * ॥ मंगलं महाश्रीः ॥ छ ॥

*

No. 186 : Triṣaṣṭiśalākāpuruṣacaritramahākāvya–Parvan VIII : Ariṣṭanemicaritra

त्रिषष्टिशलाकापुरुषचरित्रमहाकाव्यम्—अष्टमपर्व : अरिष्टनेमिचरित्रम्

Folios – 234 | Size – 24 × 2·2 inches
Language – Sanskrit | Condition – Good
Author – Hemacandrācārya | Age of MS. – V. S. 1297

General Remarks – Contains 4 excellent illustrations :

Folio 1 : Illustration of Neminātha
Folio 2 : of Ambikādevī
Folio 233 : of the Śrāvaka who got the ms. copied and of his wife.

आदिः—

॥ ॐ ॥ अर्हं ॥ ॐ नमो विश्वनाथाय जन्मतो ब्रह्मचारिणे ।
कर्मवल्लीवनच्छेदनेमयेऽरिष्टनेमये ॥

श्रीनेमेरर्हतः **कृष्णविष्णो रामस्य** सीरिणः ।
जरासंधप्रतिहरेश्चरित्रं कीर्त्तयिष्यते ॥ २ ॥

अन्तः—

द्वाविंशोऽर्हन्नथ च नवमः शार्ङ्गभृत् सीरपाणि-
स्तद्वैरी चेत्यतुलमहसः कीर्त्तिताः पर्वणीह ।

चत्वारोऽपि प्रवचनदिशं सम्यगुद्वीक्ष्य येषा-
मेकैकोऽपि श्रुतिपथगतो विस्मयाय त्रिलोक्याम् ॥ १२८ ॥

इत्याचार्यश्रीहे**मचन्द्र**विरचिते **त्रिषष्टिशलाकापुरुषचरिते** महाकाव्ये अष्टमपर्वणि बलदेवस्वर्गगमननेमिनिर्वाणपांडवनिर्वाणवर्णनो नाम द्वादशः सर्गः ॥ छ ॥

॥ ॐ ॥ सद्वृत्तादिगुणौघरत्नरुचिरः शाखाशतैर्विस्तृतो
नव्योन्मीलदखर्वपर्वकलितश्छायास्पदं भूभृताम् ।

उच्चैर्वंश इवास्ति **गूर्जरवरः श्रीमालवंशः** क्षितौ
सद्धर्मा परमेष सन्ततिफलैर्विश्वोपकारोद्यतः ॥ १ ॥

एतस्मिन् गुणरत्नरोहणगिरिर्देवप्रसादाभिधः
स्तुत्याऽनेकगुणौघरत्ननिधिभिः कोशाधिपो नूतनः ।
जातो यस्य विवेककल्पविटपी चित्तालबालान्तरे
विश्वप्राणिगणोपकारकरणप्रावीण्यमुद्राफलः ॥ २ ॥

नाम्ना **महघल**देवीति प्रिया तस्य प्रियंवदा ।
शुद्धशीला तयोः पुत्री जज्ञे पुत्रद्वयं ततः ॥ ३ ॥

सुता **मल्हणदेव्या**ख्या ठक्कुर**चाहड**प्रिया ।
विश्रान्तः संततिर्यस्याः श्रेयोभिः कीर्त्तिभाजनम् ॥ ४ ॥

देवं स्वीयगुरुं मनोज्ञवचनैर्यः स्तौति न स्वं पुनः
सर्वस्योपकृतिं तनोति नितरां न स्वस्य कस्मादपि ।
संसर्गं गुणिनां सदैव कुरुते न क्वापि पापीयसां
स श्लाघ्यो **बहुदेव** इत्यभिधया पूर्वस्तयोरंगजः ॥ ५ ॥

तत्पत्नी जिनराजचारुचरणांभोजद्वयीभृंगिका
श्रीमत्पंचनमस्कृतिस्मृतिपरप्राविण्यपुण्योन्नतिः ।
शीलाचारविचारसारमुक्ताहारावलीभूषिता
ख्याता श्री**जगदेव**मंत्रिदुहिता **शृंगारदेवी** भुवि ॥ ६ ॥

युक्तायुक्तविचारनिस्तुषमति**र्बालप्रसादः** पर-
स्तस्याऽभूत् **सुभगा**-कलत्रमभवत्तज्जन्म सूनुद्वयम् ।
आद्योऽस्तीह विशुद्धबुद्धिकलितः सूनु**र्नृसिंहा**भिधः
सौभ्रात्रप्रथितोरुवृत्तकलितोऽन्यो **रत्नसिंहा**भिधः ॥ ७ ॥

सुतत्रयं सुता चैका **बहुदेव**स्यापि संततिः ।
बालभावेऽपि यच्चित्रमबालचरितोत्तमम् ॥ ८ ॥

भक्तिव्यक्तिरभिज्ञविस्मयकरी-पित्रोस्तथा बंधुषु
शान्तिः शैशवसंगमेऽपि सुधियां केषां न दत्ते मुदम् ।
औचित्यं च पुराणपूरुषजनासाध्यं च यस्योच्चकैः
सत्पुत्रः प्रथमो विवेकवसतिः श्लाघास्पदं **छड्डकः** ॥ ९ ॥

सुधामूर्त्तिरिवान्यश्चाल्हादको **वद्दका**भिधः ।
शूरःप्रतापमार्त्तण्डस्तृतीयः **पेथडः** पुनः ॥ १० ॥

नाम्ना **नायकदेवी**ति सुतारत्नं सुताऽभवत् ।
तपस्तेजोऽद्भुतं यस्या नादपीयूषसंयुतम् ॥ ११ ॥

नाम्ना **कर्पूरदेवी**ति **छड्डकस्य** प्रियाऽभवत् ।
संग्रामसिंहस्तत्पुत्रो **हंसिका**दिसुताद्वयम् ॥ १२ ॥

नाम्ना **सहजलदेवी** गेहिनी **वद्दकस्य** च ।
धर्मरंगे यया चक्रे न प्रमादे निजं मनः ॥ १३ ॥

माघान्वयसमुद्भूत स्य पुत्रिका ।
नाम्ना **प्रतापदेवी**ति **पेथडस्य** प्रियां ततः ॥ १४ ॥

मायाजालमनित्यमत्र कलितं संसारलीलायितं
निजार्थं कुरु ।
तच्छ्रुत्वेति विभावितं विरचितं श्री**नेमिबिंबं** मया
तद्वृत्तस्य विलेखनं श्रुतिरपीदानीं क्रमात् युज्यते ॥ १५ ॥

भक्ति(?)स्वीयकुटुम्बसम्मदकृते पुण्योत्सवाकांक्षिणी
णा **शृंगारदेवी** मुदा ।
सौभाग्याद्भुतरूपचंगिमनिधिश्री**नेमिनाथ**प्रभो-
र्वृत्तं विस्मयकारि तच्च विधिना व्याख्यापयामासिवान् ॥ १६ ॥

श्रीमज्जैन....................जगती रम्यालवाल
सौरभभरश्रेयः प्रसूनव्रजः ।
अत्यानंदफलो...........प्रतिघनच्छायातपत्रद्युति-
र्यावन्नंदति तावदेष विजयीभूयाच्चिरं पुस्तकः ॥ १७ ॥

मुनिनंदशूरवर्षे१२९७ परिकलिते ।
श्री**नेमिचरित**मेत[लिखापितं वाचितं चापि ?] ॥ १८ ॥

॥ छ ॥ * ॥ मंगलं महाश्रीः ॥ छ ॥

यादृशं पुस्तके दृष्टं तादृशं लिखितं मया ।
यदि शुद्धमशुद्धं वा मम दोषो न दीयते ॥ छ ॥
शुभं भवतुं ॥ छ ॥ * ॥ छ ॥

*

No. 187 : Triṣaṣṭiśalākāpuruṣacaritamahākāvya : Parvans V—VI—VII : From Śāntinātha to Neminātha.

त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम्—पर्व ५–६–७ :

Folios – 224
Language – Sanskrit
Author – Hemacandrācārya

Size – 32 × 2·5 inches
Condition – Good
Age of MS. – c. end of 13th cent. VS.

आदिः—

ॐ ॥ अर्हं ॥ नमः श्रीशान्तिनाथाय कृतविश्वाघशान्तये ।
षोडशाय जिनेन्द्राय पंचमाय च चक्रिणे ॥ १ ॥
मोहांधकारसंदोहकर्त्तनैकविकर्त्तनम् ।
कीर्त्तयिष्यामि तस्याहं चरित्रमतिपावनम् ॥ २ ॥

अन्तः—

इत्याचार्यश्रीहेमचंद्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये सप्तमपर्वणि जयचक्रवर्त्तिचरितवर्णनो नाम त्रयोदशः सर्गः ॥ छ ॥ समाप्तं चेदं सप्तमं पर्व ॥ छ ॥

रामलक्ष्मणदशाननानमिस्तीर्थकृच्चहरिषेणचक्रभृत् ।
चक्रभृच्च जय इत्यमुत्र षड् वर्णिताः श्रुतिसुखाय संतु वः ॥ छ ॥ * ॥
विरोचनरुचिर्देयाद्विश्वेभ्यः सुदिनोदयम् ।
शिवतातिर्जिनः शांतिस्तमस्तोमोपशांतिकृत् ॥ १ ॥
श्रीचंद्रगच्छविशदांबरशीतरश्मिः श्रीमानभूदजितदेवगुरुः प्रतीतः ।
यो जंतुजातवरकैरवकाननस्य स्मेरश्रियं वितनुते तनुभिः स्वगोभिः ॥ २ ॥
यस्यास्यं कमलं नदीनममलं वेधा वेधात् शुद्धधी-
निर्दोषं विलसन्मरीचिरुचिरं नित्योदयश्रीश्रितम् ।
यत्र ब्रह्मसुता स्वयं निवसति स्वैरं श्रियः स्पर्द्धया
यज्जाड्येन विवर्जितं न च सदा रागास्पदं कुत्रचित् ॥ ३ ॥

आसीत्ततो **विजयसिंह**मुनिः प्रसिद्धः सत्याभिधः शुभविधिर्निधिरागमानाम् ।
धत्ते श्रियं समदवादिजनद्विपानां यो मानखंडनविधौ नखरायुधस्य ॥ ४ ॥

श्रीपद्मदेवनामा सूरिः श्रेष्ठस्ततः समजनिष्ट ।
जनताहृदयसरस्यां हंसा इव यद्गुणा रेजुः ॥ ५ ॥

वेधा व्यधान्नवसुधां वसुधांतरस्थां श्री**पद्मदेव**मुनिपुंगववाग्मिषेण ।
या पीयते स्म विबुधैर्न पुनस्ततान यत्तानवं नवरसप्रसरातिरिक्ता ॥ ६ ॥

तत्पादांबुजचंचरीक**परमानंदा**भिधानप्रभो-
वर्ग्देवी मुखवारिजे विजयते हस्तांबुजे श्रीरपि ।
नैवं चेत्तदभूदयं मदभरच्छेदाय किं वा दिनां
किं मौलौ करदानतोऽजनि जनः श्रेयः श्रियो भाजनम् ॥ ७ ॥

तत्पट्टोदयशैलमौलितरणिर्भूषामणिर्भूतले
स श्रीमान् **जयदेवसूरि**रभवद्भव्यांबुजोल्लासकृत् ।
उन्मीलत्कलिकालकल्मषमषीलोपस्तपःपाथसा
चक्रे येन जिनेश्वरागममहाश्रोतास्विनीजन्मना ॥ ८ ॥

तत्पादपद्मद्वितये षडंह्रि**र्जयप्रभः** सद्व्रतबद्धबुद्धिः ।
स्वश्रेयसे **शांतिजिनादिपर्व** विलेखयामास गुणैर्वरेण्यः ॥ ९ ॥

यावद्दिग्दंतिनोऽमी हृदि दधति मुदं भूतधात्री धुरायां
यावत्तिग्मांशुरंशुप्रचयपरिचयादुच्चिनोत्यंधकारम् ।
यावद्धर्मः प्रणीतः प्रसरति सततं सर्वतः श्रीजिनेंद्रैः
सम्यक् पापठ्यमानः शमिभिरभिनवं पुस्तकस्तावदस्तु ॥ १० ॥

शुभमस्तु ॥ छ ॥ समाप्तमिदं **श्रीशांत्यादिनमिपर्यंततीर्थंकराणां चरित्रम्** ॥ छ ॥

*

No. 188 : Triṣaṣṭiśalākāpuruṣacaritamahākāvya—Parvan VIII : Ariṣṭanemicaritra

त्रिषष्टिशलाकापुरुषचरितमहाकाव्य – पर्व ८ : अरिष्टनेमिचरित्र

Folios – 128
Language – Sanskrit
Author – Hemacandrācārya

Size – 34 × 2·2 inches
Condition – Good
Age of MS. – c. First half of 14th cent. V. S.

अन्तः—

॥ इत्याचार्यश्री**हेमचन्द्र**विरचिते **त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये** अष्टमपर्वणि बलदेवस्वर्गगमननेमिनाथनिर्वाणवर्णनो नाम द्वादशमसर्गः ॥ **समाप्तं चेदमष्टमं पर्व** ॥ छ ॥ समग्रनिर्ग्रंथचक्रचूडामणिश्री**कृष्णार्षि**गच्छे सुविहितशिरोमणिश्री**पद्मचन्द्रो**पाध्यायान्वये भट्टारक-श्री**पृथ्वीचंद्र**सूरयस्तत्पट्टांबरदिनकरश्री**प्रभानंद**सूरीणां सदुपदेशेन समस्तपृथ्वीतलख्याते **सुचिंतित**गोत्रपवित्रे सा० **क्षेमंधर**पुत्राः सा० **धनचंद्रमुनिचंद्रदे**पालाभिधाः। **धनचंद्र**-सुतौ **खीमसीहकाल्हा**भिधौ । **मुनिचंद्र**सुताः **छीहिलतोल्हसोमसीहहालाभिधाः** । **खीमसीह**पुत्रौ **लाडणनरपालौ** । **सोमसीह**पुत्राः सा० **धरणिग आसपाल दूलह काल्हू पारश्वा**भिधानाः । तैः सद्गुरूणां उपदेशलेशं निशम्य संसारासारतां विचार्य संवत् १३९१ वर्षे वैशाखमासे । स्वमातुः **सोमश्री**श्रेयोऽर्थं गृहीतमिदं नंदतादाचंद्रार्कं वाचकग्राहकैः सह ।

*

No. 189 : Triṣaṣṭiśalākāpuruṣacaritamahākāvya–Parvan X : Mahāvīracaritra

त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम्—पर्व १० : महावीरचरित्रम्

Folios – 266
Size – 25.2 × 2.5 inches
Language – Sanskrit
Condition – Good
Author – Hemacandrācārya
Age of MS. – V. S. 1324
General Remarks – Folio 257 missing.

आदिः—

॥ ॐ नमो वीतरागाय ॥ अर्हं ॥

नमो दुर्वाररागादिवैरिवारनिवारिणे ।
अर्हते योगिनाथाय **महावीराय** तायिने ॥ १ ॥

अथास्य देवदेवस्य देवासुरनरार्चितम् ।
चरितं कीर्त्तयिष्यामः पुण्यवारिसरोवरम् ॥ २ ॥

अन्तः—

त्रैलोक्येऽपि हि सात्त्विकेष्वनवधेः प्राग्जन्ममोक्षावधेः
श्रीमद्वीरजिनेश्वरस्य चरितं को वक्तुमीशोऽखिलम् ।
अस्ताघस्य तथापि हि प्रवचनाम्भोधेर्गृहीत्वा लवं
किञ्चित् कीर्तितमीदृशं ननु मया स्वान्योपकारेच्छया ॥ ३८५ ॥

इत्याचार्य श्रीहेमचन्द्रविरचिते **त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये** दशमपर्वणि श्रीमहावीरनिर्वाणगमनवर्णनो नाम त्रयोदशः सर्गः ॥ समाप्तं चेदं दशमं पर्व ॥ छ ॥ छ ॥ परिपूर्णमिदं **त्रिषष्टिशलाकापुरुषचरितं महाकाव्यमिति** ॥ शुभं भवतु लेखकपाठकयोः ॥ छ ॥

शिष्यो **जम्बू**महामुनेः **प्रभव** इत्यासीदमुष्यापि च
श्रीशय्यम्भव इत्यमुष्य च **यशोभद्रा**भिधानो मुनिः ।
सम्भूतो मुनि**भद्रबाहु**रिति च द्वौ तस्य शिष्योत्तमौ
सम्भूतस्य च पादपद्ममधुलिट् **श्रीस्थूलभद्रा**ह्वयः ॥ १ ॥

वंशक्रमागतचतुर्दशरत्नकोश............तस्य दशपूर्वधरो महर्षिः ।
नाम्ना **महागिरि**रिति स्थिरतागिरीन्द्रो ज्येष्ठोऽन्तिषत् समजनिष्ट विशिष्टलब्धिः ॥ २ ॥

शिष्योऽन्यो दशपूर्वभृन्मुनिवृषो नाम्ना **सुहस्ती**त्यभूद्
यत्पादांबुजसेवनात् समदितप्राज्यप्रबोधर्द्धिकः ।
चक्रे **सम्प्रति**पार्थिवः प्रतिपुरग्रामाकरं भारते-
ऽस्मिन्नर्द्धे जिनचैत्यमण्डितमिलापृष्ठं समन्तादपि ॥ ३ ॥

अजनि **सुस्थित-सुप्रतिबुद्ध** इत्यभिधयाऽऽर्य**सुहस्ति**महामुनेः ।
शमधनो दशपूर्वधरोऽन्तिषद् भवमहातरुभंजनकुंजरः ॥ ४ ॥

महर्षिसंसेवितपादसन्निधेः प्रचारभागालवणोदसागरम् ।
महान् **गणः कोटिक** इत्यभूत् ततो गंगाप्रवाहो हिमवद्गिरेरिव ॥ ५ ॥

तस्मिन् गणे कतिपयेष्वपि जातवत्सु साधूत्तमेषु चरमो दशपूर्वधारी ।
उद्दामतुम्बवनपत्तनवज्रखानिवज्रं महामुनिरजायत **वज्रसूरिः** ॥ ६ ॥

दुर्भिक्षे समुपस्थिते प्रलयवद् भीमत्वभाज्यन्यदा
भीतं न्यस्य महर्षिसंघमभितो विद्यावदातः पटे ।
योऽभ्युद्धृत्य करांबुजेन नभसा पुर्यामनैषीन्**महा-
पुर्यां** मंक्षु सुभिक्षधामनि तपोधाम्नामसीम्नां निधिः ॥ ७ ॥

तस्माद् **वज्राभिधा** शाखाऽभूत् **कोटिकगणद्रु**मे ।
उच्चनागरिकामुख्यशाखात्रितयसोदरा ॥ ८ ॥

तस्यां च **वज्र**शाखायां निलीनमुनिषट्पदः ।
पुष्पगुच्छायितो गच्छ**श्चन्द्र** इत्याख्ययाऽभवत् ॥ ९ ॥

धर्मध्यानसुधासुधांशुरमलग्रन्थार्थरत्नाकरो
भव्याम्भोरुहभास्करः स्मरकरिप्रोन्माथकण्ठीरवः ।
गच्छे तत्र बभूव संयमधनः कारुण्यराशिर्**यशो-**
भद्रः सूरिरपूरि येन भुवनं शुभ्रैर्यशोभिर्निजैः ॥ १० ॥

श्रीमन्**नेमि**जिनेन्द्रपावितशिरस्यद्रौ............संलेखनां
कृत्वाऽऽदौ प्रतिपन्नवाननशनं प्रान्ते शुभध्यानभाक् ।
तिष्ठन् शान्तमनास्त्रयोदश दिनान्याश्चर्यमुत्पादय-
न्नुच्चैः पूर्वमहर्षिसंयमकथाः सत्यापयामासिवान् ॥ ११ ॥

श्रीमान् **प्रद्युम्नसूरिः** समजनि जनितानेकभव्यप्रबोध-
स्तच्छिष्यो विश्वविश्वप्रथितगुणगणः प्रावृडंभोदवद् यः ।
प्रीणाति स्माखिलक्ष्मां प्रवचनजलधेरुद्धृतैरर्थनीरै-
रातत्य स्थानकानि श्रुतविषयसुधासारसद्यंचि विश्वक् ॥ १२ ॥

सर्वग्रन्थरहस्यरत्नमुकुरः कल्याणवल्लीतरुः
कारुण्यामृतसागरः प्रवचनव्योमांगणाहस्करः ।
चारित्रादिकरत्नरोहणगिरिः क्ष्मां पावयन् धर्मराट्
सेनानी**र्गुणसेन**सूरिरभवच्छिष्यस्तदीयस्ततः ॥ १३ ॥

शिष्यस्तस्य च तीर्थमेकमवनेः पावित्र्यकृज्जंगमं
स्याद्वादत्रिदशापगाहिमगिरिर्विश्वप्रबोधार्यमा ।
कृत्वा **स्थानकवृत्ति-शान्तिचरिते** प्राप्तः प्रसिद्धिं परां
सूरिर्भूरितपःप्रभाववसतिः श्री**देवचन्द्रो**ऽभवत् ॥ १४ ॥

आचार्यो **हेमचन्द्रो**ऽभूत् तत्पादाम्भोजषट्पदः ।
तत्प्रसादादधिगतज्ञानसम्पन्महोदयः ॥ १५ ॥

जिष्णुश्चेदिदशार्णमालवमहाराष्ट्रापरान्तं कुरून्
सिन्धूनन्यतरांश्च दुर्गविषयान् दोर्वीर्यशक्त्या हरिः ।

चौलुक्यः परमार्हतो विनयवान् श्री**मूलराजा**न्वयी
तं नत्वेति **कुमारपाल**पृथिवीपालोऽब्रवीदेकदा ॥ १६ ॥
पापर्द्धिद्यूतमद्यप्रभृति किमपि यन्नारकायुर्निमित्तं
तत् सर्वं निर्निमित्तोपकृतिकृतधियां प्राप्य युष्माकमाज्ञाम् ।
स्वामिन्नुर्व्यां निषिद्धं धनमसुतमृतस्याथ मुक्तं तथाऽर्ह-
चैत्यैरुत्तंसिता भूरभवमिति समः **सम्प्रतेः** सम्प्रतीह ॥ १७ ॥
अस्मत्पूर्वज**सिद्धराज**नृपतेर्भक्तिस्पृशोर्याच्ञया
सांगं व्याकरणं सवृत्ति सुगमं चक्रुर्भवन्तः पुरा ।
मद्धेतोरथ **योगशास्त्र**ममलं लोकाय च **द्व्याश्रय-**
च्छन्दो-ऽलंकृति-नामसंग्रहमुखान्यन्यानि शास्त्राण्यपि ॥ १८ ॥
लोकोपकारकरणे स्वयमेव यूयं सज्जाः स्थ यद्यपि तथाप्यहमर्थयेऽदः ।
मादृग्जनस्य परिबोधकृते **शलाकापुंसां** प्रकाशयत वृत्तमपि त्रिषष्टेः ॥ १९ ॥
तस्योपरोधादिति **हेमचन्द्राचार्यः शलाकापुरुषेतिवृत्तम्** ।
धर्मोपदेशैकफलप्रधानं न्यवीविशच्चारुगिरां प्रपंचे ॥ २० ॥
जम्बूद्वीपारविन्दे कनकगिरिरसावश्नुते कर्णिकात्वं
यावद् यावच्च धत्ते जलनिधिरवनेरन्तरीपत्वमुच्चैः ।
यावद् व्योमाध्वपान्थौ तरणिशशधरौ भ्राम्यतस्तावदेतत्
काव्यं नाम्ना **शलाकापुरुषचरित**मित्यस्तु जैत्रं धरित्र्याम् ॥२१॥ छ॥

॥ मंगलमस्तु ॥ शुभं भवतु लेखकपाठकयोः ॥छ॥ संवत् १३२४ वर्षे मार्गवदि १३ रवावद्येह **श्रीमदुज्जयन्यां** श्री**महावीरचरितपुस्तकं** सा० **देवसिंहेन** मातुः श्रेयोर्थं लिखा-पितम् ॥ छ ॥

॥ ॐ ॥ मदनघनसमीरः शर्मणे सोऽस्तु **वीरः**
तदनु विदितधामा **गौतम**स्वामिनामा ।
अपहरतु परेषामापदं **वैरि**शाखा
सफलितजनिताशा विश्वविश्वप्रकाशा ॥ १ ॥
तस्यां शम्बरभास्वरः कुलगृहं लक्ष्म्या समालिंगित-
श्चंचच्चन्द्रसमोदयेन मुदित...........मुक्तालयः ।

नित्यं श्रीपतिकेलिमंदिरमसौ मुक्तो न मर्यादया
संपद्दत्तघनोन्नतिर्विजयते **षंडेर**गच्छांबुधिः ॥ २ ॥

पूर्वं चाऽचलगच्छमंडनमणिः **षंडेरगच्छद्रुमो-**
त्पत्तेर्द्धामनि कामकश्मलभुवा शाली नवांभोधरः ।

जज्ञे **शान्तिमुनीश्वरः** किल शराश्वाक्ष्यब्दवृंदे गते
यद्व्याख्यागलगर्जितैरजनि भूविश्वंभरा वैभवात् ॥ ३ ॥

आचार्यदीदस्तु(?)तदीयगच्छे........भूमंडलमंडनद्रु ।
लीलावतीलोचनबाणकामवीरं विनिर्जित्य बभूव शब्दः ॥ ४ ॥

समजनि मुनिरत्नं तस्य शिष्यावतंसः
सुरपतिललनाभिः सस्पृहं गीतकीर्त्तिः ।

सुकृतिभिरभिवंद्यः श्री**यशोभद्रसूरि-**
र्नवजलधरधारांधोरणिधौतविश्वः ॥ ५ ॥

येषामाबालकालाद्विकृतिपरिहृतिर्मान्यता **मूलराजात्**
संघे मेघांबुवृष्टिः सकललिपिवचोवाचनेऽ**म्बा**निषेधः ।

षंडेरे पल्लिकाज्यानयनमथनभो........वादिकानि
श्रुत्वा नानाद्भुतानि त्रिजगति कति नो ॥ ६ ॥

क्षेमर्षिरत्राजनि चान्तराले मराललीलायितमादधानः ।
वशीकृतानेकपराजहंसशुभ्रैर्यशोभिर्धवलीकृतात्मा ॥ ७ ॥

येनोत्तुंगविशालकम्बलगिरौ............ ॥ ८ ॥

........सूरिर्जज्ञे **सुमति**रिह स ब्राह्मणवरः ॥ ९ ॥

दशवैकालिकटीका कृता च मुक्तालता [येन] ॥ १० ॥

.श्री**शान्तिसूरिर्गुणरत्नसूरिः** ।........ ॥ १२ ॥

सूरिः श्री**शान्ति**नामा गणपतिरखिलप्राणि........
स्वेच्छापूर्वं मुमुक्षोः शिवपथि यततः साधुसार्थाधिपत्यम् ॥ १६ ॥

तस्मादत्र जितेन्द्रियः शमनिधिर्विद्यावधूदर्पणः
श्रीमा**नीश्वरसूरि**रित्यभिधया वाचंयमग्रामणीः ।

यो बालोऽपि धुरं बभार महतीं धौरेयवल्लीलया
धीरः पंचमहाव्रतं प्रणयिनीं वैराग्यवीतस्पृहः ॥ १७ ॥

नवोऽस्ति सुकृती पट्टे सूरिमंडलमंडनः ।
शालिसूरिरयं नामा गुणरत्नैकरोहणः ॥ १८ ॥

इह **धर्कट**वंशेऽभूद्वरदेवोऽभिधानतः ।
निश्चितं वरदेवोऽयं पुरुषः कुलभूषणम् ॥ १९ ॥

भार्या **पूर्णम**तिस्तस्य पूर्णापूर्णमतिर्मता ।
तत्कुक्षिसंभवाः पंच तनुजाः पांडवा इव ॥ २० ॥

आद्यो **लक्ष्मीधरा**ख्योऽभूद्द्वितीयो **नागुला**भिधः ।
तृतीयः **पासडः** ख्यातश्चतुर्थः **कालिया**भिधः ॥ ३ ॥

पंचमो **जगदेवा**ख्यः सुकृती कृतिवत्सलः ।
भार्या **लक्ष्मीधर**स्याभूत् **कमलश्री**रिति नाम्ना ॥ ४ ॥

तत्कुक्षिमानसे राजहंसो **राजाक** इत्यभूत् ।
राजाकस्य मता भार्याऽ**भयश्री**रिति संज्ञया ॥ ५ ॥

तस्याः सुतद्वयं जज्ञे प्रथमोऽ**भयपालकः** ।
द्वितीयो **हरिचंद्रा**ख्यश्चन्द्रवच्चारुकान्तिभाक् ॥ ६ ॥

पासडस्य हि भार्या तु **जयश्री**रिति नामतः ।
तया सुतद्वयं जातं पुत्रिकाद्वितयं तथा ॥ ७ ॥

यथार्थेन स्वनामाऽभूत् **कुलधरो** धुरि कृती ।
द्वितीयो **देवसिंहाह्वो** देवधीर्गुरुभक्तिभाक् ॥ ८ ॥

पुत्रिका **मोहिणिः** ख्याता सदा धर्मपरायणा ।
द्वितीया सोहिणिर्जाता गुरुस्वजनवत्सला ॥ ९ ॥

कुलधरस्यापि भार्याऽऽसीत् **देवश्री**रिति नामतः ।
रूपलावण्यसंयुक्तो **नरसिंहः** सुतोऽभवत् ॥ १० ॥

नरसिंहस्य भार्याऽस्ति नाम्ना **लाडी**ति विश्रुता ।
कलत्रं **देवसिंह**स्य **देवमति**रिति श्रुता ॥ ११ ॥

तस्याः सुतद्वयं जातं पुत्रिका त्रितयं तथा ।
आद्यो **नयणसिंहाख्यो** परः **पृथिमसिंहकः** ॥ १२ ॥
पुत्रिका **मयणू**नाम्नी द्वितीया **भीमिणि**स्तथा ।
तृतीया **आल्हका** जाता स्वाजन्यगुणवत्सला ॥ १३ ॥
कलत्रं **कालियाक**स्य **धनश्री**रिव देहिनी ।
तस्याः कुक्षिसमुद्भूतौ पुत्रौ **धीणा-धरणिगौ** ॥ १४ ॥
मेइणीति तथा पुत्री **हांसिका-सांसुके** परे ।
जगदेवस्य जायाऽस्ति **जगच्छ्री**रिति संज्ञया ॥ १५ ॥
तस्याः कुक्षेस्तु संजातास्तनुजास्त्रय इहोत्तमाः ।
आद्यः **क्षेमसिंह**स्तु नांगुरश्च **वयजलः** ॥ १६ ॥
पुत्रिकात्रितयं जज्ञे **छाडी केल्ह्** च **लीलुका** ।
भार्याऽस्ति **क्षेमसिंह**स्य **रूपिणी**ति सुविश्रुता ॥ १७ ॥
जातं तत्पुत्रचतुर्थ**लक्षणो हरदेव**कः ।
तृतीयो **हरपति**र्नाम चतुर्थो **वेलुका**भिधः ॥ १८ ॥
[.... ।]
पूडाभार्या च चाहुतु तत्पुत्रः **पद्म**नामकः ॥ १९ ॥
इत्थं कुटुम्बेन समं विचिन्त्य संसारसर्वस्वमनित्यमेव ।
स्वकीयमातुः परिपुण्यहेतुं **श्रीवीरवृत्तं** परिलेखयित्वा ॥
पुस्तकं चार्पयामास **देवसिंहो** महामतिः ।
नंदताद्यावचन्द्रार्कं संघेन सह सर्वथा ॥ शुभं भवतु ॥ छ ॥

*

No. 190 : Pariśiṣṭaparvan-Sthavirāvalīcarita-mahākāvya

परिशिष्टपर्व-स्थविरावलीचरित-महाकाव्यम्

Folios – 225
Extent – Granthas 3500
Language – Sanskrit
Size – 23 × 2·2 inches
Author – Ācārya Hemacandra
Condition – Good
General Remarks – Folios 215 to 225 written on paper, dilapidated in condition.

आदिः—

श्रीमते **वीरनाथाय** सनाथायाद्भुतश्रिया ।
महानन्दसरोराजमरालायार्हते नमः ॥ १ ॥
सर्वेषां वेदसामाद्यमादिमं परमेष्ठिनम् ।
देवाधिदेवं सर्वज्ञं **श्रीवीरं** प्रणिदध्महे ॥ २ ॥
कल्याणपादपारामं श्रुतगंगाहिमाचलम् ।
विश्वाम्भोजरविं देवं वंदे **श्रीज्ञातनन्दनम्** ॥ ४ ॥
पान्तु वः **श्रीमहावीरस्वामिनो** देशनागिरः ।
भव्यानामान्तरमलप्रक्षालनजलोपमाः ॥ ५ ॥
त्रिषष्टिशलाकापुंसां दशपर्वा विनिर्मिता ।
इदानीं तु परिशिष्टपर्वास्माभिः प्रतन्यते ॥ ६ ॥
अत्र च जम्बूस्वाम्यादिस्थविराणां कथोच्यते ।
विश्वस्य कण्ठालंकारकृते हारावली शुभा ॥ ७ ॥

अन्तः—

इत्याचार्यश्री**हेमचन्द्र**विराचिते **परिशिष्टपर्वणि** स्थविरावलीचरिते महाकाव्ये आर्यरक्षितव्रतग्रहणपूर्वाधिगमवज्रस्वामिस्वर्गगमनतद्वंशविस्तारवर्णनो नाम द्वादशमः सर्गः समाप्तः ॥ **समाप्तं परिशिष्टपर्व** ॥ ग्रंथसंख्या ३५००

*

No. 191 : Triṣaṣṭiśalākāpuruṣacaritamahākāvya-Parvan I : Ṛṣabhadevacaritra

त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम्–पर्व १ : ऋषभदेवचरित्रम्

Folios – 513 स्तो ल्ह ३ Size – 15 × 2·2 inches

Language – Sanskrit Condition – Good

Author – Hemacandrācārya Age of MS. – First half of 13th cent. V. S.

General Remarks – Folio 100 सु, 200 स्त, 300 स्ता, 400 स्तो, 500 स्तो. A lecture was delivered at a village called *Ghūsaḍī* in V.S. 1240 on the basis of this ms. This ms., therefore, is written before this date.

अन्तः—

इत्याचार्यश्री**हेमचंद्र**विरचिते **त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये** प्रथमे पर्वणि मरीचिरुपभाविशलाकापुरुषभगवन्निर्वाणभरतनिर्वाणवर्णनो नाम सर्गः ॥

समाप्तं च श्रीऋषभस्वामिभरतचक्रवर्त्तिप्रतिबद्धं प्रथमं पर्व ॥ छ ॥ * ॥

॥ ॐ ॥

सुधर्मस्य ततो ज्ञान ज्ञानात्तस्य परिग्रहः ॥ १ ॥
तस्माद्भवंति श्रेयांसि स्थैर्यस्य........... ।
.................तस्माद्धर्मपरिणतिः ॥ २ ॥
तस्माद्धर्मोपदेशश्चोपदेशाद्धर्मविस्तृतिः ।
ततोऽनेकभवं तीर्त्वा लभंते च परं पदम् ॥ ३ ॥
इत्यनेकगुणं ज्ञानं......................... ।
सर्वेषामेव धर्माणां ज्ञानदानफलं महत् ॥ ४ ॥ चतुर्भिः कलापकम् ॥

तथा ह्युक्तं च-

ज्ञानदानेन जानाति जंतुः स्वस्य हिताहितम् ।
वेत्ति...................च समश्नुते ॥ ५ ॥
ज्ञानदाता त्ववाप्नोति केवलज्ञानमुज्ज्वलम् ।
अनुगृह्याखिलं लोकं लोकाग्रमधिगच्छति ॥ ६ ॥
ऋते ज्ञानात्कथं जंतु................ ।
अज्ञानी जनुषांधवत् कथं वर्त्तेत सत्पथि ॥ ७ ॥
........माहात्म्यं ज्ञानदानस्य सद्गुरोरिति ।
श्री**सर्वाणंद**सूरीणामुपासकेन सव........ ॥ ८ ॥
...................च **घूसडी**ग्रामवासिना ।
लिखितं श्राद्धधर्मेण **चरित्रमृषभप्रभोः** ॥ ९ ॥
यावद्भूर्भूधरो मेरुर्यावच्चंद्रदिवाकरौ ।
यावज्जिनेंद्र...............त् सुपुस्तकः ॥ १० ॥ छ ॥

मंगलं महाश्रीः ॥ छ ॥ वत्सरे श्रीविक्रमार्कद्वादशवेदांबराधिके (१२४०)। व्याख्यातं **घूसडीग्रामे**...........

*

No. 192 : Triṣaṣṭiśalākāpuruṣacaritamahākāvyam-Parvans II-III.
त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम्—पर्व २-३

Folios – 224
Language – Sanskrit
Author – Hemacandrācārya

Size – 17 × 2·5 inches
Condition – Good
Age of MS. – V. S. 1295.

अन्तः—

इत्याचार्यश्रीहेमचंद्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये तृतीये पर्वणि श्रीशीतलस्वामिचरितवर्णनो नामाष्टमः सर्गः ॥ छ ॥ समाप्तं च तृतीयं पर्व । छ ॥ * ॥

श्रीसंभवप्रभृतितीर्थकृतां तृतीयेऽष्टानां चरित्रमिह पर्ववरेऽष्टसर्गे ।
ध्येयं पदस्थमिव वारिरुहेऽष्टपत्रेऽनुध्यायतो भवति सिद्धिरवश्यमेव ॥ छ ॥

मंगलं महाश्रीः ॥ छ ॥ संवत् १२९५ वर्षे अश्विन वदि २ रवौऽद्येह श्रीवीजापुरपत्तने समस्तराजावलीपूर्वकं तपाकीयश्रीपोषधशालायां चारित्रगुणनिधानसमस्तसिद्धांतकालान्मा-नेन पारगत तपा० देवभद्रगणिमलयकीर्त्ति पं० कुलचंद्र पं० देवकुमारमुनि नेमिकुमार-मुनिप्रभृतिसमस्तसाधून् तच्चरणकमलान् भक्तपरमश्रावकसाधु० रतनपाल समस्तसिद्धांत-पुस्तकानां पौषधशालाभारनिर्वाहक परमश्रावकश्रेष्ठि वील्हणद्वितीयभारनिर्वाहकसाधर्मिकानां वात्सल्यतत्परपरमश्रावक ठ० आसपालतृतीयभारनिर्वाहकनिरंतरं पुस्तकसिद्धांतनिर्विकल्प-भक्त्या सारतत्परपरमश्रावकसाधु० लाहडप्रभृतीन् समस्तश्रावकैः त्रिषष्टिपुस्तकं समस्तसाधून् श्रावकाणां पठनवाचनपुण्यश्रेयोऽर्थं लिखापितम् ॥ छ ॥ लेखकपाठकानां शुभं भवतु ॥ छ ॥ मंगलं महाश्रीः ॥ * ॥ शिवमस्तु ॥ छ ॥ आचंद्रार्कमयं पुस्तकं नंदतु ॥ छ ॥ मंगलं महाश्रीः ॥ छ ॥ * ॥

*

No. 193 : Triṣaṣṭiśalākāpuruṣacaritamahākāvya : Parvan IV

त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम्—पर्व ४

Folios – 293
Language – Sanskrit
Author – Hemacandrācārya

Size – 14·5 × 1·7 inches
Condition – Good
Age of MS. – c. Latter half of 13th cent. V. S.

*

No. 194 : Triṣaṣṭiśalākāpuruṣacaritamahākāvya-Parvan III

[From Sambhavajina to Śītalanātha]

त्रिषष्टिशलाकापुरुषचरितमहाकाव्य—पर्व ३ : सम्भवजिन—शीतलनाथ.

Folios – 127
Language – Sanskrit

Extent – Granthas 4660
Size – 15·7 × 2.2 inches

Author – Hemacandrācārya
Age of MS. – c. First half of 14th cent. V. S.
Condition – Good
General Remarks – Folios 6, 7, 8, 15 and 16 missing.

आदिः—

ॐ अर्हं

त्रैलोक्यप्रभवे पुण्यसंभवाय भवच्छिदे ।
श्रीसंभवजिनेंद्राय मनोभवभिदे नमः ॥ १ ॥
धात्रीपवित्रीकरणं लवित्रं कर्मवीरुधाम् ।
चरित्रमथ वक्ष्यामि श्रीसंभवजिनेशितुः ॥ २ ॥

अन्तः—

इत्याचार्यश्रीहेमचंद्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये तृतीये पर्वणि श्रीशीतलस्वामिचरितवर्णनो नामाष्टमः सर्गः ॥ छ ॥ समाप्तं च तृतीयं पर्व ॥

श्रीसंभवप्रभृतितीर्थकृतां तृतीयेऽष्टानां चरित्रमिह पर्ववरेऽष्टसर्गे ।
ध्येयं पदस्थमिव वारिरुहेऽष्टपत्रेऽनुध्यायतो भवति सिद्धिरवश्यमेव ॥ छ ॥

*

No. 195 : Triṣaṣṭiśalākāpuruṣacaritamahākāvya–Parvan VII : Munisuvrataswāmicaritra & Rāmāyaṇa

त्रिषष्टिशलाकापुरुषचरितमहाकाव्य—पर्व ७ : मुनिसुव्रतस्वामिचरित्र तथा रामायण

Folios – 280
Language – Sanskrit
Author – Hemacandrācārya
Age of MS. – V. S. 1318
Extent – Granthas 2888
Size – 17 × 2 inches
Condition – Good

आदिः—

॥ अर्हं ॥ उं नमः सर्वज्ञाय ॥

अथ श्रीसुव्रतस्वामिजिनेंद्रस्यांजनद्युतेः ।
हरिवंशमृगांकस्य तीर्थे संजातजन्मनः ॥ १ ॥
बलदेवस्य पद्मस्य विष्णोर्नारायणस्य च ।
प्रतिविष्णो रावणस्य चरितं परिकीर्त्यते ॥ २ ॥

अन्तः—

इत्याचार्यश्रीहेमचंद्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये [सप्तमपर्वणि....

........जयचक्रवर्त्तिचरितवर्णनो नाम त्रयोदशः सर्गः ॥ छ॥ **समाप्तं चेदं सप्तमं पर्व** ॥ छ॥ रामलक्ष्मणदशाननेनेमिस्तीर्थकृच्च हरिषेणचक्रभृत् ।

चक्रभृच्च जय इत्यमुत्र षड् वर्णिताः श्रुतिसुखाय संतु वः ॥ छ ॥ ग्रंथाग्रंथ ३८८८ ॥ छ ॥ सं० १३१८ वर्षे ज्येष्ठशुदि २ रवावद्येह दंडाहीपथ.. पतिमहाराजाधिराजश्रीअर्जुनदेवकल्याणविजयराज्ये तन्नियुक्तमहं० श्रीसोमप्रतिपत्तौ ठकु० वीकम्वसी...............................लिखितेयमिति ॥ छ ॥

यादृशं पुस्तके दृष्टं तादृशं लिखितं मया ।
यदि शुद्धमशुद्धं वा मम दोषो न दीयते ॥ छ ॥

लेखकपाठकयोः ॥ छ ॥

शिवमस्तु सर्वजगतः ॥ छ ॥ मंगलं महाश्रीः ॥ छ ॥ शुभं भवतु ॥ छ ॥

*

No. 196 : Triṣaṣṭiśalākāpuruṣacaritamahākāvya-Parvan X : Mahāvīracaritra

त्रिषष्टिशलाकापुरुषचरितमहाकाव्य—पर्व १० : महावीरचरित्र

Folios – 243
Language – Sanskrit
Author – Hemacandrācārya
General Remarks – Incomplete. Almost all the folios have stuck together.

Size – 16.7 × 1.7 inches
Condition – Injured
Age of MS. – c. Latter half of 13th cent. V.S.

*

No. 197 : Triṣaṣṭiśalākāpuruṣacaritamahākāvya-Parvan X : Mahāvīracaritra

त्रिषष्टिशलाकापुरुषचरितमहाकाव्य—पर्व १० : महावीरचरित्र

Folios – 327
Language – Sanskrit
Age of MS. – c. First half of 14th cent. V.S.

Size – 16.2 × 2.2 inches
Author – Hemacandrācārya
Condition – Good

General Remarks – Folios 23, 24, 26–30, 63, 66, 67, 75, 77, 79–81, 95, 102–104, 108, 111, 112, 125, 126, 142, 145, 148, 149, 153–160, 163, 164, 166, 167, 170, 189, 195, 196, 199, 200, 201, 203, 205, 207, 210, 211, 214, 221, 224, 226, 227, 229, 230, 236, 240, 243, 245, 252–256, 265, 269, 282, 285–287, 290–292, 295, 296, 302, 306, 307, 311–314, 316, 317, 322, 323, 325, 326 are missing.

अन्तः—

वणिजां भरतख्यातो धर्कटानां धरातले ।
वंशोऽस्ति चारुपत्रश्च सुपर्वैः समलंकृतः ॥ १ ॥

सार्द्धद्वादशसंख्येयाः ज्ञात्यो **नगरा**भिधाः ।
बभूवुस्तस्माद्वंशा वटशाखेव विश्रुताः ॥ २ ॥

डिंड्वानकात्समुद्भूता वणिजत्वेऽपि **डिंड्डुहाः** ।
विख्याताः संति सर्वत्र गच्छोऽस्ति तत्पुराभिधः ॥ ३ ॥

आसीत्तस्मिन् वणिग्वंशे **नेमाकः** पुरुषाग्रणीः ।
देवश्रीवल्लभा तस्य पुत्रैकं द्वेच पुत्रिके ॥ ४ ॥

तदंगभूरभूच्चारुः श्रेष्ठी **पारस**नामकः ।
पद्मिनी दयिता तस्य सती साध्वी शुभाशया ॥ ५ ॥

शाकंभरीमंडलगगनभानुः श्री**धर्मघोषः** समजनि प्रबुद्धः ।
मिथ्यात्वविरतं सद्धर्मनिरतं परमार्हतं **पारसकं** चकार ॥ ६ ॥

सम्यक्त्वरत्नविभूषितांगे सर्वज्ञपूजनदानचंगे ।
नेमाकविग्रहजे प्रसिद्धे जाते सदा **पूनिणि** सड्ढिकारव्ये ॥ ७ ॥

जज्ञाते नंदनौ द्वौ च ताभ्यां सद्धर्मतत्परौ ।
बोधाकः प्रथमो नाम **वाग्भटश्च** तथाऽपरः ॥

बोधाकस्य भवेद्भार्या **मल्हणदेवी**ति विश्रुता ।
प्रत्यक्षा कथ्यते **आई** जिनधर्मैकनिश्चला ॥ ८ ॥

जाता **वाग्भटस्येव मदनश्रीः** प्रथमा प्रिया ।
द्वितीयदयिता जज्ञे **देवी देसल**पूर्वकाः ॥ ८ ॥

लाडी साल्ही सुते स्यातां **पारसस्य** महात्मनः ।
बालस्याद्विधवा भूयात् **लाडी** सधर्मवत्सला ॥ ९ ॥

रत्नत्रयवत् संजातं वयं तस्याः सुतत्रयम् ।
कार्कटो नृपतिस्तेजा यथासंख्यममी सुताः ॥ १० ॥

देसलाया सुता जाताश्चतस्रो गुलमालयः ।
प्राच्यपाची प्रतीची च उदीची च यथाक्रमम् ॥ ११ ॥

लक्ष्मीवल्लक्ष्मीः प्रथमा **राजी** राजीवलोचना ।
तृतीया नयना चैव तुर्या **कर्पूरिका** स्मृता ॥ १२ ॥

काकटः प्रथमस्तेषां यः सदा पापसंकठः ।
विकटो धर्मसंग्राहे कंकटं सत्यभाषणे ॥ १३ ॥
परोपकारे निरतो निरंतरं दयापरो यः शुचिमानसः सदा ।
नृणां पतिः केन गुणेन वर्ण्यते दाने वृषे यस्य निरालसा मतिः ॥ १४ ॥
अकलितगुणगेहं यः सदा धर्मदेहं नरपतिरभिधानं सत्यशीलप्रधानः ।
जिनमुनिपदभक्तः सिष्टसंगे प्रयुक्तः अबुधजनवियुक्तः सम्यकत्वैकचित्तः ॥१५॥
देवपूजार्चने नित्यं यस्य गच्छंति वासराः ।
श्रद्धावान् दर्शनासक्तः तेजाको भव्यश्रावकः ॥ १६ ॥
....

*

No. 198 : Triṣaṣṭiśalākāpuruṣacaritamahākāvya–Parvan X : Mahāvīracarita

त्रिषष्टिशलाकापुरुषचरितमहाकाव्य—पर्व १० : महावीरचरित

Folios – 4–295
Language – Sanskrit
Author – Hemacandrācārya
Size – 18 × 2.5 inches
Condition – Good
Age of MS. – c. First half of 14th cent. V. S.

General Remarks – Somewhat incomplete.

*

No. 199 : Śatapadī Vṛtti [शतपदीवृत्ति]

Folios – 200
Language – Sanskrit
Author – Dharmaghoṣasūri–Mahendrasūri
Extent – Granthas 5200
Size – 15.7 × 2.5 inches
Condition – Good
Age of MS. – c. Beginning of 14th cent. V.S.

General Remarks – Folio 1 contains an illustration of Bhagavān; folio 2, of 14 dreams; folio 199, of the four-fold Saṅgha comprising of male and female lay-followers of Jainism etc., listening to the exposition of the preceptor seated along with his disciples. Folio 200 has an illustration of the Samavasaraṇa. The background of all these four excellent pictures is red and white, yellow, green and black colours have been utilised therein.

आदिः—

ॐ ॥ नमः श्रीमद्देवगुरुपदपंकजेभ्यः ।

त्रिभुवनगृहप्रदीपः कल्याणनिधिर्भवोदधौ द्विपः ।
संशीतितिमिरभानुर्जयति श्रीमान् जिनो वीरः ॥ १ ॥

पूर्वपक्षशतं कश्चित् सूरिश्चक्रे सदर्पधीः ।
विदधे श्रीधर्मघोषसूरिरुत्तरविस्तरम् ॥ २ ॥

सिद्धांतवचनैः प्रायः क्वचित्ताद्दक्षयुक्तिभिः ।
अपि प्रकरणैः क्वापि सिद्धांतार्थानुयायिभिः ॥ ३ ॥

ते च पूर्वपक्षा अमी ।

अन्तः—

इति शाश्वताष्टाह्निकाविचारः ॥ छ ॥ ११७ ॥ शिवमस्तु अध्यापयितृअध्येतृव्याख्यातृश्रोतृभ्यः । समाप्ता चेयं **शतपदिकाभिधाना** विषमविषमतरकतिपयविचाराणां प्रश्नोत्तरपद्धतिरिति ॥ छ ॥ इयं च विक्रमाद्गुणरसमाससंख्ये वर्षे १२६३ **श्रीमदार्यरक्षितसूरि**शिष्याणां श्रीमज्**जयसिंहसूरी**णां पट्टालंकृतिकर्तृभिः श्री**धर्मघोषसूरि**भिर्विदब्धा । ततश्च तामतिगंभीरार्थत्वात् व्युत्पन्नमतीनामेव सुखावबोधां तदितरेषां तु किंचिदायासगम्यामवगम्य ततस्तेषामेव श्री**धर्मघोषसूरि**णां श्रुतांतेवासिभिरपि तत्पट्टप्रतिष्ठितैः श्री**महेन्द्रसिंहसूरि**भिर्विक्रमादुदधिग्रहसूर्यसंख्ये संवत्सरे ॥ छ ॥ १२९४ सैव ग्रंथपद्धतिः क्वचिदाधानं क्वचिदुद्धरणं क्वचित् क्रमविरचनां च विधाय कानिचिदधिकान्यपि प्रश्नोत्तराणि प्रक्षिप्य सुकुमारमतीनामपि सुखावबोधा भवत्विति किंचिद्विस्तरवती विदधे ॥ छ ॥ भद्रमस्तु ॥ चतुर्विधस्य संघस्य ।

यावन्नंदति तीर्थं भरतक्षेत्रे जिनस्य वीरस्य ।
तावन्नंदत्वेषाऽपि वाच्यमाना सदा विबुधैः ॥ छ ॥

पंचश्लोकसहस्राणि तथोपरि शतद्वयम् । अस्मिन् शतपदिकाग्रंथे प्रमाणमिदमीरितम् ॥छ॥ अंकतोऽपि ग्रंथाग्रं ५२०० ॥ इति **शतपदिकाभिधाना प्रश्नोत्तरग्रंथपद्धतिः समाप्तेति** ॥ शुभं भवतु ॥ छ ॥

*

No. 200 : (1) Padmānandamahākāvya–Jinendracaritamahākāvya Part I: Ādināthacaritra

(१) पद्मानन्दमहाकाव्य-जिनेन्द्रचरितमहाकाव्य–प्रथम खंड : आदिनाथचरित्र

Folios – 319
Language – Sanskrit
Author –Amaracandrasūri Vāyaḍacacchīya

Size – 32.5 × 2.2 inches
Condition – Good
Age of MS. – c. Latter half of

General Remarks – Folio 1 contains an illustration of Śrī Ṛṣabhadevaswāmin, 3.1 × 2 inches in size. On folio 2 is an illustration, 2.9 × 2 inches in size, depicting Minister Padma requesting the Preceptor, Pt. Amaracandra, to compose the Padmānanda-kāvya. A monk is seen behind the Preceptor.

आदिः—

॥ स्वस्ति श्रीर्जयोऽभ्युदयश्च ।

अर्हं नौमि सदार्हत्यकारणं सकलार्हतः ।
स्वस्तिंश्रीजयदं श्रीमन्महानंदमहोदयम् ॥ १ ॥
मुदाऽर्हामि तदार्हन्त्यं भूर्भुवःस्वस्त्रयेश्वरम् ।
यदाराध्य ध्रुवं जीवः स्यादर्हन् परमेश्वरः ॥ २ ॥
अर्हतः स्थापनानामद्रव्यभावैश्चतुर्विधाः ।
चतुर्गति भवोद्भूतं भयं भिंदंतु भाविनाम् ॥ ३ ॥
जयत्यादिमतीर्थेशस्त्रिलोकीमंगलद्रुमः ।
श्रेयःफलं सदा लोका यदालोकादुपासते ॥ ४ ॥....
हित्वा संसारहेतूनि यो रत्नानि चतुर्दश ।
स्वीचक्रे मुक्तिदां रत्नत्रयीं शांतिः स वोऽवतात् ॥ १९ ॥........
पायाद्वः पूरयन् पांचजन्यं नेमिजिनेश्वरः ।
बलानुजबलाटोपकीर्त्तिं कवलयन्निव ॥ २५ ॥........
मौलौ फणिफणाः सप्त नयश्रीभिः करा इव ।
धृताः शांतरसास्वादे यस्य पार्श्वः स पातु वः ॥ २६ ॥
यदंह्रिस्पर्शनान्मेरुर्विलोलैः सानुबाहुभिः ।
धन्यंमन्यो ननर्त्तेव तं वीरस्वामिनं नुमः ॥ २७ ॥........
श्रीनागेंद्रकुलाराममंडनं चंदनद्रुवत् ।
गच्छः श्रीवायटीयोऽस्ति गौरसौरभगौरवः ॥ ३२ ॥
गच्छेऽस्मिन् समजायंत श्रीमद्रासिलसूरयः ।
न च कुर्यद्गुणाः केषां जिह्वादोलासु खेलनम् ॥ ३३ ॥
सूरिः श्रीजीवदत्ताह्वस्तत्पट्टोदयपर्वतम् ।
प्राप्यार्कवद्भवां भारैर्जगद्भाव.नभासयत् ॥ ३४ ॥

सूरिः श्रीजिनदत्ताख्यः प्रख्यातस्तत्पदेऽभवत् ।
भव्यानां भवदावार्तिर्ययौ यद्वचनामृतैः ॥ ३५ ॥

नामभिस्त्रिभिरेभिः स्युर्भूयो भूयोऽपि सूरयः ।
गच्छेऽस्मिन् वत्सरे वर्षाशीतोष्णाः समया इव ॥ ३६ ॥

आनुपूर्व्याऽनया श्रेयोराशिः श्रीरासिलोर्गुरुः ।
भूयो भवद्भवारण्ये पुण्यवाणीसुधासरः ॥ ३७ ॥

ते कदापि चतुर्मासकल्पकल्पनया स्थितिम् ।
अकल्पयन्निलाकल्पकल्पेऽणहिल्लपत्तने ॥ ३८ ॥

तत्र श्रीरासिलाचार्यास्तांश्चतुर्मासकस्थितान् ।
भव्या विज्ञपयामासुरिदं विशदवासनाः ॥ ३९ ॥

चतुर्विंशतितीर्थेशचरित्राणि यतिप्रभो ! ।
मासैश्चतुर्भिरस्माकं नय श्रोत्रसुधोर्मिताम् ॥ ४० ॥

कर्ण्यमाकर्ण्य तद्वाक्यं मुनिर्मुद्वल्लिमंजरीम् ।
श्रवणाभरणीचक्रे भाविनामिति भारतीम् ॥ ४१ ॥

सूरेः श्रीजिनदत्तस्य मद्गुरोः शिष्यपुंगवः ।
श्रयत्यमरचंद्राह्वो मम सब्रह्मचारिताम् ॥ ४२ ॥

श्रीपद्मेनार्थितः स श्रीजिनेन्द्रचरिताह्वया ।
वाक्सहायो महाकाव्यं निर्ममे निर्ममेश्वरः ॥ ४३ ॥

तत्रोक्ताऽस्ति चतुर्विंशत्यर्हतां चरितावली ।
श्रावकाः श्रावयेतां वः श्रवणामृतसारणिम् ॥ ४४ ॥

श्रीपद्ममंत्री कुत्रासौ वंशे मुक्तामणीयते ? ।
इत्युक्ते श्रावकैः सूरिरूरीचक्रे पुनर्वचः ॥ ४५ ॥

अत्रैवाऽणहिल्लपुरे वायटज्ञातिसंभवः ।
वासुपूज्यः सतां पूज्यः समभून्मंत्रिवृत्रहा ॥ ४६ ॥

तथा कर्णपथायातैर्जगच्चित्तानि यद्गुणैः ।
पूर्णान्यमांत एवांतर्यथा जिह्वासु तेऽलसन् ॥ ४७ ॥

तद्भूरभूद्धियांधाम **रामदेव** इति श्रुतः ।
यन्ममौ यन्मनोऽणौ खं तत्कीर्त्तिस्तत्र मातु किम् ॥ ४८ ॥

आसीत्तस्य सुतः शांतस्वान्तः **शांतड**संज्ञया ।
मुखाब्जमधुवाग् यस्य बुधालिप्रीणनं व्यधात् ॥ ४९ ॥

आसलः कथयामास तत्सूनुः सकलाः कलाः ।
पर्वेन्दुरिव किं त्वस्या नश्वरी कीर्तिकौमुदी ॥ ५० ॥

अहिदेवीति तस्याऽऽसीत् पत्नी यस्या मनोऽविशत् ।
न दुर्वृत्ततमोदीप्रप्रत्यंह्रिनखदीपकम् ॥ ५१ ॥

तयोर्जयति श्रीसद्म **पद्म**नामा तनूद्भवः ।
धर्मः श्रित्वा शरण्यं यं कलित्रस्तोऽस्तभीरभूत् ॥ ५२ ॥

पद्मस्य स्मेरता युक्तं यन्मित्राभ्युदये भवेत् ।
राजप्रसादतो रेजे यदस्य श्रीस्तदद्भुतम् ॥ ५३ ॥

लक्ष्मीं पुष्णाति **पद्म**स्य धर्मः प्राग्भवसेवितः ।
तत्कृतज्ञस्तमेवासो तद्दानादेव सेवते ॥ ५४ ॥

श्रेयांसि बहुविघ्नानि तस्य नासन् यतोऽकृत ।
श्रेयोन्तराय घाताय श्रेयोंऽतरशतानि सः ॥ ५५ ॥

यथा तेनार्थितोऽत्यर्थमकरो**दमरो मुनिः** ।
चरित्राणि जिनेन्द्राणां शृणुत श्रावकास्तथा ॥ ५६ ॥

अर्हच्चरितशुश्रूषासुभगं भावुकाशयः ।
अमरेंदुमुनिं पद्मः स कदाप्यब्रवीदिदम् ॥ ५७ ॥

भवसंभारसंस्कारभावितो भवतामहम् ।
न विभिन्नो भवाम्येव भवभाजां स्वभाववत् ॥ ५८ ॥

कृपावंतो भवंतोऽपि कदापि हि न मां हृदः ।
बहिः कुर्वन्ति सर्वज्ञसिद्धांतमिव तात्त्विकाः ॥ ५९ ॥

भवलक्षप्ररूढस्य प्रौढपुण्यतरोः फलम् ।
साधुमूर्द्धन्य ! धन्यस्य भवत्संगोऽभवन्मम ॥ ६० ॥

चतुर्विंशतितीर्थेशचरित्रश्रवणोत्सव: ।
मत्पुण्यवनपर्जन्य: पूर्यतां त्वत्प्रसादत: ॥ ६१ ॥

निशम्य तद्वच: सम्यगमरो मुनिरब्रवीत् ।
हृद्वर्तिशमपीयूषपयोधिलहरीं गिरम् ॥ ६२ ॥

तीर्थंकरचरित्राणां तीर्थंकरजुषामपि ।
तीर्थंकरागमार्थानां प्रथा धर्मकथा मता ॥ ६३ ॥

संवेगं विंदते नांगी निर्वेदं नैव विंदति ।
संवेदयति नानंदशर्म धर्मकथां विना ॥ ६४ ॥

तत्त्वं सात्त्विकताकंदमहानंदमहोदया: ।
कथ्यमाना मया तथ्या: पथ्या धर्मकथा: शृणु ॥ ६५ ॥

चतुर्विंशतिरर्हन्तो ह्यधिका दश चक्रिण: ।
प्रत्येकं नव बलिनो विष्णव: प्रतिविष्णव: ॥ ६६ ॥

त्रिषष्टिरवसर्पिण्यां शलाकापुरुषा इति ।
इहासन् भरतक्षेत्रे भूतसंभाविसिद्धय: ॥ ६७ ॥

अन्त:—

इति **जिनदत्तसूरि**शिष्यपंडितश्री**मदमरचंद्र**विरचिते श्री**पद्मानंदा**परनाम्नि श्री**जिनेन्द्रचरिता**भिधाने **महाकाव्ये** वीरांके श्री**आदिनाथचरिते** मरीचिस्वरूपभगवन्निर्वाणवर्णनो नामाष्टदशम: सर्ग: ॥

सोऽव्याद्वो **वृषभप्रभु**र्भवततौ सेवां बभारेव या
तां संत्यज्य चिराद्विरागललितो लोकस्थितिं यद्यपि ।
एक: शाश्वतमुक्तिशर्म किमपि प्रापत् पदं य: परं
सांतर्भावभृता तथाऽपि किल यं ज्ञाने निलीनान्वगात् ॥ १ ॥

देवा यांत्यमृताशनैरमरतां श्रीपद्म वेद्मि ध्रुवं
श्रीदेवी समदा कदापि न ततस्त्वां मोक्तुमुत्कंठते ।
येनासौ सुकृतामृतै: प्रतिपदं संतर्पमाणान्वया
संप्राप्नोत्यजरामरत्वमतुलं तत्त्वां कुतो मोक्ष्यति ॥ २ ॥ छ ॥

ग्रंथाग्रं श्लोक ३३६ ॥

यदक्षरपरिभ्रष्टं मात्राहीनं च यद्भवेत् ।

क्षंतुमर्हथ विद्वांसः ! कस्य न स्खलिता मतिः ॥ शुभं भवतु ॥ छ ॥

*

(2) Padmānandamahākāvya–Jinendracaritamahākāvya–Part II : Abridged Caturviṁśatijinacarita etc.

(२) पद्मानन्दमहाकाव्य–जिनेन्द्रचरितमहाकाव्य–खंड २ : संक्षिप्त चतुर्विंशतिजिनचरितादि

Folios – 99
Extent – Granthas 2000
Language – Sanskrit
Size – 32·5 × 2·2 inches
Author – Amaracandrasūri Vāyaḍagacchīya
Condition – Good
Age of MS. – c. Latter half of 14th cent. V. S.
General Remarks – Folio 98 contains an illustration of Bhagavān Mahāvīraswāmin, 3·3 × 2·2 inches in size. On folio 99 is depicted Śrī Amaracandrasūri expounding the Padmānandacarita to Minister Padma, 3.2 × 2.2 inches in size.

आदिः—

ॐ ॥ स्वस्तिश्रीर्जयोऽभ्युदयश्च ॥

श्रेयोवल्लिवनांकुराः कुजनतश्रेणीपिधानेऽर्गला
मोहद्रोहणमुद्गराः शिवसुखारोहे महारज्जवः ।
अंहःसंहतिजैत्रधर्मविजयस्तंभाः शुभं भाविनां
पुष्यासुर्वृषभप्रभोः पदनखप्रासोदया रश्मयः ॥ १

पूर्वं श्रीऋषभादीनामर्हतां चरितानि ते ।
पुरः श्रीपद्म ! संक्षेपाद् वक्ष्ये विस्तरतस्ततः ॥ २

श्रीपद्म ! प्रथयिष्यामि प्रथमं पुरतस्तव ।
श्रीमद्वृषभचरित्रं त्रयोदशभवाद्भुतम् ॥ ३

अन्तः—

आनंदास्वादसीमा सुजनजनहृदां भाग्यसौभाग्यसीमा
विश्वालीलोचनानां परमशमरसस्याद्भुतैश्वर्यसीमा ।
धर्मस्योल्लाससीमा शिवसुखपटलीसंश्रयोपायसीमा
श्राद्धानां शर्म संवर्द्धयतु जिनविभोर्वर्द्धमानस्य मूर्त्तिः ॥ २८० ॥

इत्याचार्यश्रीजिनदत्तसूरिशिष्यपंडितश्रीमदमरचंद्रविरचितानि चतुर्विंशतिजिनेन्द्रचरितानि समाप्तानि ॥ छ ॥ * ॥ ग्रंथाग्रं श्लोकसंख्या १८०२ अक्षर १६ ॥ छ ॥

अथ प्रशस्तिः—

श्रीमद्वायटनाम्नि सारसुकृतश्रीधाम्नि पुण्ये महा-
स्थाने माननिदानमानसरसाः श्रीवायटीया द्विजाः ।
स्तोमस्तोमसमुत्थधूमनिवहैर्मालिन्यमालंबया-
मासुर्या वणिजो जिनार्चनघनोद्यद्धूपधूमोत्करैः ॥ १ ॥

ध्वजमिषभुजमूलस्थूलकुंभैकवक्षोरुहमहह महीयोऽधःकृतस्फाटिकाद्रिः ।
विलसति वणिजां सत्कीर्त्तिधर्मार्द्धनारीश्वरवपुरिव तत्र श्रीमहावीरचैत्यम् ॥२॥

श्रीश्वेतांबरमौलिमौक्तिकमणिस्तस्मिन् जिनेन्द्रालये-
ऽधिष्ठाता जिनदत्तसूरिरजनि ज्ञानैकवैज्ञानिकः ।
श्रेयस्तुंगयदंगसंगमसमुद्भूतप्रभूतस्फुर-
त्पुण्यैः पश्य गुणैर्गतं दिवि सितच्छायैरुडुच्छद्मना ॥ ३ ॥

तत्पट्टोर्वीधरवरमणिर्द्योमणिद्योतजैत्रै-
स्तेजःपुंजैः किमपि ककुभोऽपूरि रासिल्लसूरिः ।
यस्य व्योमच्छलकलशिभृत्कीर्तिधारापयोभि-
र्गोभिःभुक्ताःक न जनमनःकामने मोहवल्ल्यः ॥ ४ ॥

सुरगजरजनीभुजंगगंगाभुजगपतिप्रतिशूरकीर्त्तिपूरः ।
तदनु मुनिपतिर्मतिप्रतिष्ठाजनितरसोऽजनि जीवदेवसूरिः ॥

वयस्यद्विद्याभिः खलु सह कलाभिर्गुणगणाः
सहेलं खेलंतो बहुमतिलते यत्तनुवने ।
यशःश्रीपुष्पस्रक्चयसुरभयः संशयमयीं
महादोलां मुक्त्वा सुकृतरसवापीषु विहृताः ॥ ८ ॥

महायोगी भोगिप्रभुनिभभुजस्तस्य शमिनः
सभायामायातः क्वचिदहनि कश्चिद्दहनदृग् ।
असावुद्यद्विद्याचयजयपताकामिव सुखं
मुखाज्जिह्वां क्लृप्त्वा कृतपरिकरोऽग्रे न्यवीशत ॥ ९ ॥

प्रीतिव्यालोलमौलिच्छलचलकमलामुच्छलन् न्युंछनालि-
व्याजभ्राजिष्णुवीचिं स्तिमिततिमिसदृक्दृक्कलाकेलिकम्राम् ।

अक्षुभ्यंस्तत्प्रभावादपि सुकृतसुधासिंधुधाराधरोऽयं
दूरं सूरिः पुपूरे सर इव वरवाग्वृष्टिभिः संसदं सः ॥ १० ॥

अथ सुकृतकथांते गंतुमिच्छन् रसज्ञां
न स परिकरबंधात् क्रष्टुमीष्टे स्म योगी ।
भषण इव तदस्मिन्नुल्लसद्दीनशब्दे
किमिदमिति जनेनापृष्टमाचष्ट सूरिः ॥ ११ ॥

शक्तेः पातयितुं नभस्तलफलं हुंकारतोऽर्कं क्षमो
मूलस्तंभमपि त्रिलोकभवने भंक्तुं भुजंगेश्वरम् ।
योगीन्द्रोऽद्भुतभूरिसिद्धिरसिकोऽसौ मत्कपालाप्तये
प्राप्तः स्तंभनमाचरन् मयि मया द्राक् प्रत्युत स्तंभितः ॥ १२ ॥

वक्त्राग्रलंबितलसद्रसनावबद्धपर्यस्तिकोऽत्र मदमर्षदवानलेन ।
कुंजार्धनिसृतमहोरगवेष्टितांगः शाखीव शुष्यतुतरामयमित्थमेव ॥ १३ ॥

जिनेश्वरमतामृतार्ण्णवविर्तद्रचंद्रोदय प्रमोदय दयां हृदि क्रुधममुं च मुंच प्रभो !
सदः सदि वदत्यदस्तदनु साधुवर्गे गुरुं क्षितौ खटिकयाऽक्षराण्यलिखदेष
योगी तदा ॥ १४ ॥

उपकृतिमुपकर्त्तुः सर्वतः कुर्वते ये कति धरति न धात्री तानसौ मानसौंडान् ।
अपकृतिकृति यस्तामेव कुर्वीत गुर्वीं वहति सततमुर्वीमुद्विवेकः स एकः ॥ १५ ॥

आमृश्यैवं स यतिपतिना कृष्णभोगीव योगी
बंधान् मुक्तः क्रुधमधिवहन् निःश्वसन् निस्ससार ।
यातो यस्यां दिशि रिपुरसौ गम्यतां नाद्य तस्या-
मस्मद्वर्ग्यैरिति च वचनं स्पष्टमाचष्ट सूरिः ॥ १६ ॥

रतिरिव पतिनाशे श्रीरिवास्थैर्यदोषे
स्ववशगकविदौस्थ्ये वागिवापत्रतं या ।
नगरबहिरगच्छद् गच्छसाध्वी न्यवेशि
स्वतनुमनु च तेन द्रोहिणा मोहिता सा ॥ १७ ॥

मत्वेत्यथो कुशम तमयं मुनीशः
कृत्वा ततान वितते तपनस्य तापे ।

स प्रस्फुरज्ज्वरभरोऽथ विहाय साध्वीं
लूनांगुलिर्गलितगर्वगुणो जगाम ॥ १८ ॥

अयमुदयदमंदव्यक्तशक्तिर्व्यनक्ति
क्वचन वचनसंगी नास्य सादृश्यसंगीः ।

सततमिति यतींदोस्तस्य नर्नर्त्ति कीर्त्ति-
र्जगति जगति गंगार्णस्तरंगांगहारैः ॥ १९ ॥

पूर्वोर्वीधरगंधसिंधुरशिरःसिंदूरपूरप्रभां
बिभ्राणे तरणौ कदाचन कृतप्राभातिकप्रक्रियः ।

सूरिर्भूरिभिरेत्य तत्पुरचरैः सम्मान्य मान्यः सतां
प्रीतिश्रीरसभावितैर्निजसभावर्त्ती बभाषे द्विजैः ॥ २० ॥

गौरेका पतिता कथंचन मृता श्रीब्रह्मशालांतरे
न म्लेच्छाः प्रविशंति तत्र न मृतं कर्षन्ति विप्राः पशुम् ।

धर्माधारकृपाधुरीण ! तरसा तस्मादहो कश्मला-
दस्मानन्यपुरप्रवेशकलयैवोत्कर्षतः कर्ष तत् ॥ २१ ॥

मंत्राकृष्टविशिष्टचेटकवयत्रातांगयष्टिर्यति-
स्वामी सोऽन्यपुरप्रवेशनमथ ध्यानं दधौ शुद्धधीः ।

सा गौरुच्छ्वसिता ततो जिनमतस्यापि प्रभावप्रभा
सा श्रीब्रह्मगृहाद्बहिर्निरगमद्दुःखं द्विजानां हृदः ॥ २२ ॥

स्वस्थानस्थापितात्मा तदनु मुनिरसावुत्सवेन द्विजेन्द्रै-
रानिन्ये ब्रह्मशालामथ च पृथुमदेर्वायटादित्यदेवम् ।

हैमं यज्ञोपवीतं तदिह सह महास्थानवंटेन दत्त्वा
जैनोऽपि ब्रह्ममुख्यस्त्वमसि शमनिधेऽस्माकमेवं जगे च ॥ २३ ॥

जलद इव तडित्वान् मेरुशृंगाप्तसेतु-
र्जलधिरिव करीवाबद्धकल्याणकक्षः ।

ध्वनिभरभृतदिक्को लब्धनिष्कोपवीत-
स्तदनु मुनिरकार्षीद्धर्मकर्मोपदेशम् ॥ २४ ॥

पदपदमदगायद्गायनस्तोमनृत्य-
न्नटपटलकजल्पद्वंदिवृंदादद्भुतेन ।
मुदितजनमुदश्रुस्निग्धसांद्रेण सूरिः
स्वमठमथ पथाऽगाज्जग्मुरन्येऽप्यथौकः ॥ २५ ॥

यतींदोस्तस्याथोल्लसदसमशक्तेः परपुर-
प्रवेशावेशर्द्धिः परमतममुत्कर्षमगमत् ।
अमुक्तस्वांगोऽपि स्वसनसुभगस्यापि यदसा-
वनेकस्याऽप्येकः समसमयमेवांतरविशत् ॥ २६ ॥

यन्मार्गाग्रतृणालिरिक्षुलतिका यद्वालुकामंडलं
खंडो यत्तटगर्त्तनीरममृतं यत्कर्करा शर्करा ।
यत्फेनप्रचयः सुधारुचिरयं यत्संरवोऽनाहत-
ध्वानस्ताः शतशोऽस्फुरन् क नयते तस्य प्रबंधापगाः ॥ २७ ॥

तेनाकारि पुरारिपर्वतशिरोधिक्कारिधात्रीतला-
लंकारि स्फुटपापहारि भुवने वृंदं जिनेंद्रौकसाम् ।
आरोपोन्नमितेन यस्य नियतं दंडोच्चयेनोच्चकैः
विद्धं व्योम दधाति किं न परितश्छिद्राण्युडुच्छद्मना ॥ २८ ॥

गांभीर्ये च गुरुत्वे च माधुर्ये च ध्वनौ च कः ।
पर्यन्ताब्धेर्जलाधार इव तस्यैतु तुल्यताम् ॥ २९ ॥

श्राद्धान् श्रद्धाभाजनमुदितसभाजनविराजिनो विप्रान् ।
पौरांश्च भक्तिगौरान् कदाचिदाचष्ट स मुनीन्द्रः ॥ ३० ॥

ग्रहीतुमतुलाग्रहः परपुरप्रवेशव्यसोः कपालमपपालनाद्वपुष एकखंडं मम ।
सयोगिपुरुषोऽकृत प्रमृतगोप्रयोगं मया स्वरक्षणविचक्षणान्वघटि चेटकानाघटाः ॥३१॥

भुवनविजयविद्यां शुद्धकर्मण्यवद्याममुमदसुविनाशैः साधयिष्यन् स योगी ।
चिरविरचितयत्नो मत्कपालग्रहार्थं विहरति परितो मन्मृत्युकालप्रतीक्षः ॥ ३२ ॥

व्यसोर्नगरनिर्गमे डमरकध्वनिर्व्योमनि स्फुटः स्फुरति तद्यदा मम शिरोऽस्थि चूर्ण्यं तदा ।
इतीद्धमतिलीलया समुदमुद्वहन् मुचितां चिराय परिपूरयत्यगुरुचंदनौघैः पुरा ॥ ३३ ॥

इति विरचितशिक्षः स क्षमी ध्यानशुद्धि-
त्रुटितविकटकर्मा निर्मलीभूतचित्तः ।
अमृगयत नटंतीरष्टसिद्धीः कदाचि-
द्दिशि विदिशि कदाचिद्धीःश्रियौ युक्तपाणी ॥ ३४ ॥

नेत्रे निमील्यति चेद्भववृद्धिहेतुर्भूलोकदर्शनभिया स पतिर्यतीनाम् ।
तद्भूरिभावभरभासुरभूतिमालामालोकते त्रिजगतीमपि किं करोतु ॥ ३५ ॥

इति सुकृतनिधानध्याननिर्धारितायुः भुवमिव दिवमात्माध्यासपूतां स चक्रे ।
जनमनसि स जीवन्नेव रेजे तु तत्तन्मतिविफलितताद्दग्दुष्टयोगिप्रयोगः ॥ ३६ ॥

अमीभिस्त्रिभिरेव श्री**जिनदत्ता**दिनामभिः ।
सूरयो भूरयोऽभूवंस्तत्प्रभावास्तदन्वये ॥ ३७ ॥

एकः प्रौढविवेकविभ्रमलतापुष्पेषु पुष्पेषुजित्
तेषु श्री**जिनदत्त**सूरिरुदयद्भूरिप्रभावोऽभवत् ।
ताद्दग्विस्तृतहृन्निपीतनभसो यस्योचितं द्युिते
धीरांभोधरसिंधुसिंधुरजयी व्याख्यासु शब्दो गुणः ॥ ३८ ॥

श्रीविवेकविलासाद्यैर्यत्प्रबंधैः सहस्रशः ।
हृतमोहतमोऽकारि करैरिव रवेर्जगत् ॥ ३९ ॥

आयुष्यं कथयंति जंतुषु पयःसारः पयोधेः पुनः
पीयूषं पृथिवीजुषामनिमिषीभावाय संभाव्यते ।
विद्मः श्री**जिनदत्तसूरि**वचनं सारः सुधानामपि
व्यक्तं मुक्तिमपि प्रयच्छति सतां यत्पीतमुत्प्रीतिकृत् ॥ ४० ॥

श्रीजीवदेवसूरीणां त एव परमाणवः
जग्मुर्यदंगतां भेजे तद्गुणैस्तद्धियेव सः ॥ ४१ ॥ इतश्च—

श्री**वायट**प्रवणवंशमणिर्महस्वी श्री**वासुपूज्य** इति मंत्रिवरो विरेजे ।
येना**ऽणहिल्लपुर**पौरपरंपराणां चूडामणित्वमुररीक्रियते स्म शश्वत् ॥ ४२ ॥

रामदेव इति तत्सुतोऽभवद्यद्यशःप्रसरदुग्धवारिधौ ।
लक्ष्मलक्षदरसोमशुक्तिजा मौक्तिकाल्य इवोडुपंक्तयः ॥ ४३ ॥

तस्य मानसनिवासिनी प्रिया **पद्मिनी** सुदिवसोद्गमस्मिता ।
श्रीगृहांह्रिनन करांह्रिनीरजा जातरूपरुचिरा व्यराजत ॥ ४४ ॥

तस्य सूनुरजनिष्ट **शांतडः** शांतलक्ष्मशशलक्ष्मसन्निभैः ।
यस्य निस्तमसि मानसे गुणैः शर्मधर्मनृपतिर्लसन् ललौ ॥ ४५ ॥

कलिकालकरालवल्गितैः गतसंज्ञं सुकृतामृतोर्मिभिः ।
सहजी समजीवयत्तमां दयिता तस्य पतिव्रताव्रतम् ॥ ४६ ॥

आसलः कलयति स्म कौशलं कासु कासु न कलासु तत्सुतः ।
केवलं स्वगुणभाषणार्थिनां रक्षणे परविभाषणेऽल्पधीः ॥ ४७ ॥

तस्याहिदेविरतिदेहधरेव गेहलक्ष्मीः प्रिया कलविलक्षणलक्षणाऽऽसीत् ।
यस्या वरांह्रिनखरत्नधरो मनोब्धिः केनापि नैव कलितो विमलात्मवृत्तिः ॥४८॥

श्रीपद्म इत्यभिधया धियां निधिः पुत्रस्तयोर्जयति मंत्रिवृत्रहा ।
श्रीः प्राप्य तीर्थमिव यं सरस्वतीपूतं स्वपापचपलत्वमत्यजत् ॥ ४९ ॥

कश्चिद्वीरगुणोऽस्ति यः स कलितोन्मादं विवादं मया
दत्तामित्यखिलेषु यस्य यशसा विश्वेषु विस्फूर्जितम् ।
क्वाप्येतत् प्रतिमल्लतां कलयते कोपीनकोपीत्यदात्
ब्रह्मेंदुं जयपत्रमस्य पुरतः संलक्ष्य लक्ष्माक्षरम् ॥ ५० ॥

सत्पात्रप्रसराश्रयः शुचिगणप्राग्भारगौराशयः
सद्वृत्तौ द्विजराजहंससुखकृद्दोषाकरे न्यग्मुखः ।
श्रीमद्विश्वलदेवविश्वविभुना प्रोद्भास्य तेजोभरैः
श्रीपद्मस्तपनेन पद्मवदयं सद्मश्रियो निर्ममे ॥ ५१ ॥

श्रीमद्विश्वलमेदिनीश्वरकृतप्रौढप्रसादादसौ
व्यापारानधिगम्य कानपि कदाऽप्युत्सेकदावांबुदः ।
श्रीपद्मो नृपतिप्रजार्थयुगलीं कृत्वाऽर्थशास्त्रार्थतः
स्वार्थं सारपरोपकारकरणव्यापारमेवाकरोत् ॥ ५२ ॥

श्रीपद्मः समभूषयज्जिनविभुं हृन्नंदनैश्चंदनैः
कर्पूरैः कुसुमोत्करैः सुरभिभिः शुभ्रैर्यशोभिर्जगत् ।

तस्याग्रे दुरितोच्चयैः सह समुच्चिक्षेप कृष्णागुरुं
तं स्तौति स्म नवस्तवैरतुलवंसोऽपि त्रिलोक्या स्तुतः ॥ ५४ ॥

साधर्मिकोद्धरणसुश्रमणादिसंघप्रोत्सर्पणाप्रवचनप्रवणानुरागैः ।
चैत्यार्पितैश्चमरकांचनकुंडलाद्यैः श्रीजैनशासनसमुन्नतिमेष तेने ॥ ५५ ॥

तस्य पुष्यति सतीत्वसंपदं चंपलेति सहधर्मचारिणी ।
सेवते सुकृततत्पराऽपरा पद्मलाऽपि गुलसद्मतद्मनः ॥ ५६ ॥

चित्ताह्लादं प्रह्लादनदेव्यप्यस्य प्रियाऽकरोत् ।
धर्मरूपः सदा यस्या स एवाऽऽसीन्मनोंतरा ॥ ५७ ॥

पुत्रोऽस्य विक्रमादित्यः पद्मलाकुक्षिसंभवः ।
कलाभिश्च प्रभाभिश्च सुधांशुरिव वर्द्धताम् ॥ ५८ ॥

सौभाग्यदेवी कुलभाग्यदेवी श्रीपद्ममंत्रिद्युपतेः स्वसाऽस्ति ।
गंगेव या निर्मलशीललीला जडस्वभावं न बिभर्त्ति किंतु ॥ ५९ ॥

श्रीपद्ममंत्रीश्वरभागिनेयो मोषाकसूनुर्महणाह्वयोऽस्ति ।
तारुण्यचारुण्यपि यस्य देहे वृद्धत्वशुद्धा विधयो वसंति ॥ ६० ॥

मल्लदेवो हस्तिमल्लः प्रतिमल्लः लसद्यशाः ।
निजान्वयवनीसिंहो देवसिंहो महोद्यमः ॥ ६१ ॥

पूर्णेन्दुद्युतिलुंटाककीर्त्तिरूदाक इत्यपि ।
सहोदराः क्रमादेते त्रयो महणमंत्रिणः ॥

श्रीमत्तीर्थकृतां चरित्रततयश्चित्राश्चतुर्विंशतेः
स्वल्पाभिस्तिथिभिः यथा श्रुतिपथे पांथत्वमातन्वते ।
ग्रंथः कोऽपि तथा भवेद्यदि ततः श्राद्धाः श्रयंत्येव तं
शृण्वन्तः सुकृतानि पद्मसचिवेंद्रस्येति चेतस्यभूत् ॥ ६२ ॥

श्रीमद्वायटगच्छवारिजरवे पादारविंदद्वये
येन श्रीजिनदत्तसूरिसुगुरोः शृंगारभृंगायितम् ।
स श्वेतांबरमौलिरत्नममरः श्रीपद्ममंत्रीप्सितं
पद्मानंदमिदं मुदाऽकृत महाकाव्यं महानंदकृत् ॥ ६३ ॥

क्षिप्त्वा कर्मविपाकवीरनिचयं निःश्रेयसाख्यं पदं
प्राप्ताः प्रेंखदनंतसंततचिदानंदोर्मिसंवर्मिताः ।
यावत्तीर्थकराः करामलकवत् पश्यंति विश्वस्थितिं
तावद्ग्रंथवरोऽस्त्वसौ बुधहृदि श्रेयःसुधास्वस्तिकः ॥ ६४ ॥ छ ॥

इत्याचार्यश्री**जिनदत्तसूरि**शिष्यपंडितश्रीमद्**मरचंद्र**विरचिते **महाकाव्ये श्रीजिनेन्द्रचरिते श्रीपद्मानंदापरनाम्नि** वीरांके प्रशस्तिसर्गः समाप्तः ॥ छ ॥

खेलंतींदुधिया मुखे भ्रुवि लसन्निस्त्रिंशलेखाशया
नीलेंदीवरसंशयाद् दृशि गिरां भारेऽब्धिवीचिभ्रमात् ।
मत्तेभप्रभुहस्तीविभ्रमतया बाहौ करेंभोरुह-
भ्रांत्याऽस्यैव सदैव **पद्म**सचिवं श्रीर्देवता सेवताम् ॥ छ ॥

ग्रंथाग्रं श्लोकसंख्या ११५ ॥ छ ॥ मंगलं महाश्रीः । शुभं भवतु ॥ छ ॥

*

No. 201 : Śāntināthacaritramahākāvya—Padya

शान्तिनाथचरित्रमहाकाव्य—पद्य

Folios – 246
Language – Sanskrit
Author – Munidevasūri
Size – 27·7 × 2 inches
Condition – Good
Age of MS. – c. Beginning of 14th cent. V. S.

General Remarks – Folio 246 is broken. Folio 2 contains an illustration of Goddess Sarasvatī with a lute and a book in her upper and lower left hands respy. and a lotus in her upper right hand, the lower right one being kept in the *Āśīr-mudrā* or blessing posture.

॥ ॐ नमः श्रीशान्तिनाथाय ॥

आदिः—

वेश्मरत्ननिशारत्ननभोरत्नपरंपरम् ।
परं जयति तज्ज्योतिर्महामोहतमोपहा ॥ १ ॥
नोड्डीनो यन्मनोमूषास्थितः शान्तो रसाधिपः ।
स श्री**वृषभ**योगीन्द्रः श्रियेऽष्टापदसिद्धिभाक् ॥ २ ॥
नमः श्री**शान्तये** भेजे यं मृगः श्रितवत्सलम् ।
सिंहिकासुतवित्रस्तो वनेऽपि गगनेऽपि च ॥ ३ ॥

व्याख्यासु पान्तु श्रीनेमेर्दंतद्युतिजुषस्त्विषः ।
नमन्मूर्द्धसु बिभ्रत्योऽक्षतदूर्वाक्षताश्रियम् ॥ ४ ॥

श्रीमत्पार्श्वः प्रभुः सप्ततत्त्वक्कोटीश्वरः श्रिये ।
उर्ध्वीकृता ध्वजा यस्य फणव्याजाच्चकासति ॥ ५ ॥

यो बाल्ये मेरुवंशाग्रेऽनर्तयत्कीर्तिनर्तकीम् ।
तं श्रीवीरं तपःश्रीणां नाट्याचार्यमुपास्महे ॥ ६ ॥

ब्रह्मगुप्तिसनाथस्य यतिधर्मस्य मूर्त्तयः ।
एकोनविंशतिः सन्तु तेऽजिताद्या जिना मुदे ॥ ७ ॥

एकामपि त्रिरूपां यो जगत्रितयगोचरे ।
चारयामास जैनीं गां गौतमः स तमश्छिदे ॥ ८ ॥

श्रीसुधर्मा सुधर्मश्रीर्वीरवंशसमुद्भवः ।
तरो महांतरारातिपातने तनुतां मम ॥ ९ ॥

चतुर्दशमितापूर्वपूर्वरत्नकुलाश्रयः ।
विश्वरूपं दधन्मध्येश्रुतवार्द्धि प्रवर्द्धताम् ॥ १० ॥

चतुर्दशशतग्रंथग्रथनायासलालसम् ।
हारिभद्रं वचो हारि भद्रं भद्रं करोतु नः ॥ ११ ॥

वादविद्यावतोऽद्यापि लेखशालामनुज्झता ।
देवसूरिप्रभोः साम्यं कथं स्याद्देवसूरिणा ॥ १२ ॥

वन्दे श्रीदेवचन्द्रं तं यत्कृतं प्राकृतं बृहत् ।
श्रीशान्तिवृत्तं संक्षिप्य संस्कृतं क्रियते मया ॥ १३ ॥

अमानं महिमानं कस्तस्य स्तोतुं गणेशितुः ।
शिष्यो यस्योदितो हेमचन्द्रसूरिर्जगद्गुरुः ॥ १४ ॥

नृपतिप्रतिबोधिन्या यद्गिरासुधयाऽमराः ।
जज्ञिरे पशवोऽपि श्रीहेमचन्द्रं महेम तम् ॥ १५ ॥

श्रीदेवानंदसूरिभ्यो नमस्तेभ्यः प्रकाशितम् ।
सिद्धसारस्वताख्यं यैर्निजं शब्दानुशासनम् ॥ १६ ॥

श्रीदेवानन्दशिष्यः श्री**कनकप्रभ**शिष्यराट् ।
श्रीप्रद्युम्नश्चिरं नंद्यात् ग्रंथस्यास्य विशुद्धिकृत् ॥ १७ ॥

लक्ष्यं क्षामत्वलक्ष्मभ्यां गोस्तनीरजनीशयोः ।
सारं विरिंचिना हृत्वा कृताः सन्तो जयन्तु ते ॥ १८ ॥

मैत्रीपात्रं मनो येषां सुधाकृतसुधा गिरः ।
कायः परोपकाराय तेभ्यः सद्भ्यो नमो नमः ॥ १९ ॥

वस्तु सद्वस्तुसंसर्गान्निर्गुणं लभते गुणम् ।
पंगुरप्यर्कसंपर्कादरुणः किं न वर्ण्यते ॥ २० ॥

अद्भुतप्रतिभाभूत्या मृजन्तः काव्यदर्पणम् ।
न ये स्वहस्तमालिन्यं गणयन्ति जयन्ति ते ॥ २१ ॥

न निन्द्यः सोऽपि निःस्नेहः कठिनः कश्मलः कटुः ।
गोमण्डलोपकारेण खलो गोरसवृद्धिकृत् ॥ २२ ॥

तावन्न काव्यरत्नस्य भवेत्तेजोऽधिकाधिकम् ।
यावद् द्विजिह्वजिह्वाग्रशाणायां नैव घृष्यते ॥ २३ ॥

ज्वल्यमानं खलज्वालाजिह्वज्वालाभजिह्वया ।
सकर्णकर्णाभरणं काव्यहेम भवत्यहो ॥ २४ ॥

परोपकारणं धर्मोऽर्थस्तु सत्कर्मकौशलम् ।
अर्थसार्थकता कामो मोक्षस्त्वेतेषु सत्तमः ॥ २५ ॥

पुरुषार्थान् यथायोगं पुरुषो योजयन्निमान् ।
उपायानिव सामादीन् राजते राजसन्निभः ॥ २६ ॥

मध्ये चतुर्णामेतेषां यस्यैकोऽपि न विद्यते ।
मर्त्त्यमूर्त्तिधरः स्पष्टं स्पष्टगीः पशुरेव सः ॥ २७ ॥

अथ चैतेषु सर्वेषु धर्मः स्वर्गापवर्गदः ।
यदाराधनतः सर्वा संपत्तिः पत्तितां भजेत् ॥ २८ ॥

स चानेकविधः सप्तक्षेत्रवित्तव्ययादिभिः ।
परं विज्ञायते सर्वः सिद्धान्तश्रवणाग्रहात् ॥ २९ ॥

सिद्धांतस्यापि देष्टारोऽर्थतस्तीर्थकरा मताः ।
अतः पावयतात्मानं तदीयचरितामृतैः ॥ ३० ॥
एतेष्वप्यधुना वक्ष्ये स्वपरोकृतेः कृते ।
चरितं **शांतिनाथस्य** चक्रिणो धर्मचक्रिणः ॥ ३१ ॥ तथा हि—

अन्तः—

....
पूर्वोदयाद्रिरत्नं कमलोल्लासी जगत्त्रितयदीपः ।
सुदिनोदयाय भवतु श्री**शांतिः**सकललोकस्य ॥ १ ॥
कल्याणमूर्त्तिर्विबुधो.............................. ।
..........................मेरुप्रतिमः समस्ति ॥ २ ॥
पुत्रस्तस्याऽप्यजनि जनतानंदकंदः सदैव
न्यायोपात्तं स्वधनमनिशं दत्तवान् दानशौंडः ।
लोके लोकं..........................

*

No. 202: Śāntināthacaritramahākāvya—Padya

शान्तिनाथचरित्र महाकाव्य—पद्य

Folios – 189
Language – Sanskrit
Author – Munidevasūri

Extent – Granthas 4855
Size – 30·7 × 2 inches
Condition – Good
Date of Composition – V. S. 1322

Age of MS. – V. S. 1338.

अन्तः—

धीरोदात्तचरित्रवानधिगतश्चक्रिश्रियं तत्र यद्
भोगेऽप्यस्य न संगमंगति मतिस्तद्धीरशांतो ध्रुवम् ।
शूरः क्रूरतरश्च मोहनिहतौ धीरोद्धतो नायकः
सिद्धो बद्धरतिश्च धीरललितः **शांतिः** शिवायास्तु वः ॥ १ ॥
बार्हस्पत्याधिपत्यस्य पातने प्रथितोद्यमः ।
अपूर्वः कोऽपि लोकेऽस्मिन् **देवसूरिः** कृतोदयः ॥ २ ॥

यो वादीश्वरदेवसूरिसुगुरोर्मूलक्रमे सूरिणा
चक्रे श्रीमदनेंदुना निजपदे तेनाग्रवृत्तश्रिता ।
काव्ये श्रीमुनिदेवसूरिकविना श्रीशांतिवृत्ते कृते
श्रीप्रद्युम्नमुनींदुधीरुचिशुचिः सर्गोऽगमत् सप्तमः ॥ ३ ॥ छ ॥
निर्वृतिप्राप्तिर्नाम ॥ छ ॥

प्रभाधिनाथैर्मुनिभिः कलाभृन्मुख्यैरुपेतो गुरुतारकौघैः ।
अनंतलीलाकलितः किलाऽऽस्ते गच्छो बृहद्गच्छ इति प्रतीतः ॥ १ ॥

तत्र चित्रचरितः परितापं हर्तुमब्द इव भव्यजनानाम् ।
सस्यवृद्धिकरसंवरवानप्युज्ज्वलोऽजनि गुरुर्मुनिचंद्रः ॥ २ ॥

दुःषमाजलधौ येन मग्ना सुविहितस्थितिः ।
हेलयैव समुद्दध्रे धरित्री वादिपोत्रिणा ॥ ३ ॥

श्रीजैनशासनसरोजविकाशभानुः श्रीदेवसूरिरिति तस्य बभूव शिष्यः ।
दुर्वादिकौशिकचयप्रतिभादृशांध्यं यो वाग्मरीचिनिचयै रचयांचकार ॥ ४ ॥

येषां दूरीकृतया कीर्त्यावल्याऽपि कुमुदचंद्रस्य ।
विदधे विजयस्तज्जयमहिमा को नाम तेषां स्यात् ॥ ५ ॥

तद्भद्रासनविंध्यभूभृति यशः श्रीपूर्वगंगाभृति-
श्रीभद्रेश्वरसूरयः समभवन् भद्रेभशोभाभृतः ।
यैः प्रज्ञाप्रसरेण शास्त्रगहनं संशोध्य दुःसंचरं
शिष्याणां मतयः करेणव इव प्रौढप्रचाराः कृताः ॥ ६ ॥

तत्पदेऽभयदेवस्य प्रभोः कल्पद्रुकल्पताम् ।
कथैव कथयत्येषा प्ररूढा रत्नमंजरी ॥ ७ ॥

सूरिर्मदनचंद्राख्यो मुख्यो मार्दवशालिनाम् ।
तत्पट्टमुकुटो रेजे शिष्यरत्नैः समुज्ज्वलैः ॥ ८ ॥

मत्वा छिन्ने येन नाम्नी स्वकीये लब्ध्वा सद्यौ पुष्पचापद्विजेशौ ।
नेशौ मन्ये मुख्यकर्तुं विरुद्धाऽन्येकोऽनंगः कृश्यदंगः परोऽभूत् ॥ ९ ॥

तत्पट्टैकविशेषको गणभृतः प्रद्युम्नतः कोविद-
स्तद्बंधोर्जयसिंहसूरिसुगुरोर्योगादिनिर्णीतधीः ।

शास्त्रेषु प्रचितो मनीषिभुवनात् पद्माकरैर्णैधितः
काव्यं श्री**मुनिदेवसूरि**रस्त श्री**शांतिवृत्तं** नवम् ॥ १० ॥

द्विद्वित्र्येकसमासु १३२२ मासि सहसिश्वेतद्वितीया बुधे
द्वेधाऽप्यत्र यदाश्रयं श्रितवता काव्यं मयेदं कृतम् ।

श्रीप्रद्युम्नमुनीश्वरः स विशदं सद्यः प्रसद्य व्यधाद्
ज्ञैरन्यैरपि शोधनीयमसमं धृत्वा ममत्वं मयि ॥ ११ ॥

ग्रं० ४१६ एवं ग्रं० ४८५५ ॥ छ ॥

प्रत्यक्षरं च संख्यानात् पंचपंचाशताऽधिका ।
अस्मिन्ननुष्टुभामष्टचत्वारिंशच्छती ध्रुवम् ॥ छ ॥

मंगलमस्तु ॥ छ ॥ सं० १३३८ वर्षे आषाढ शुदि १५ शनौ ॥ छ ॥

ॐ ॥ नमः सर्वज्ञाय ॥

स श्री**शांतिः** श्रिये वोऽस्तु योऽपूर्वो मृगलांछनः ।
अविनाशिरुचिच्छायः सदोद्योतः प्रकाशकः ॥ १ ॥

सश्रीकं जिनमावहन् लवणिमालीलागृहं रत्नसू
राज्ञः पूर्णकलामवाप्य मुदितस्तन्वन्नदीनां स्थितिम् ।
शश्वद्गोत्रप्रतिष्ठारुचिरसनिलयः साधुवृत्तः समग्रः-
सत्त्वाधारः समुद्रोपम इह जयति **प्राग्वाट**नामाऽन्वयः ॥ २ ॥

तदन्वयेऽभूद्धनदानुकारी सन्मार्गशाखीव परोपकारी ।
धनेश्वरो धर्मधुरीणदेहस्तस्यांगजोऽभूद्**धनदाक**नामा ॥ ३ ॥

काशह्रदे वरनगरे **धनदाकेनादिनाथजिनभवने** ।
मूलप्रतिमाऽभिनवाऽस्थाप्यत शुद्धेन चित्तेन ॥ ४ ॥

श्रेष्ठिनो **धनदाक**स्य **ब्रह्मदेवः** सुतः शुभः ।
वाग्भटश्च सुता चैका **लक्ष्मणिः** शीलशालिनी ॥ ५ ॥

पुत्रो **गोगाक**नामाऽभूद्वाहडस्य गुणश्रियः ।
गां(? गो)गाकस्य मलापत्नी तयोः पुत्रत्रयं क्रमात् ॥ ६ ॥

ऊथिग-धांधु-आकडमुख्या **साल्हू** तथा दुहिता ।
सौभाग्य-श्रीदेवी द्वाभ्यां पत्न्यौ सुभाकारे ॥ ७ ॥

भार्याऽभूद्ब्रह्मदेवस्य मंदोदरी शुभाशया।
तयोः पुत्राश्चतुस्संख्याः धर्मकर्माणि कर्मठाः ॥ ८ ॥

आल्हाकः सकलः कलंकरहितः स्वच्छाशयो धर्मधीः
माल्हाको महिमानिधानमतुलो वाक्येन सन्नंदकः।
राल्हाको गुरुपादपद्मभसलः सर्वज्ञपूजारतः
साल्हाकः सबलः सलीलगमनः सत्यव्रतालंकृतः ॥ ९ ॥

राल्हाककुमरदेव्योः पुत्रत्रितयं तु **ब्रह्मणागाद्यः**।
काल्हूक-रत्नसिंहौ ब्रह्मी-सोहगसुते द्वे च ॥ १० ॥

आल्हाकोऽर्जितवित्तादाभरणं श्री**युगादिदेवस्य**।
आरात्रिकं च मंगलदीपयुतं कारयामास ॥ ११ ॥

आल्हाकरत्नदेव्यो रत्नत्रयधारकास्त्रयः पुत्राः।
समधरगुणधरयशधरमुख्याश्चाहणि सुता चैका ॥ १२ ॥

समधरभार्याकर्मणिपुत्राः सप्त क्रमेण **कोलाकः**।
आसा-ऽऽसपाल-सेढा-पूना-हरिचंद्र-वयराख्याः ॥ १३ ॥

गुणधरभार्या स्वच्छा शीलतपोदानभावधर्मरता।
राजमतिरंगजातास्तयोर्जनानंदकाः सप्ताः ॥ १४ ॥

पार्श्वभटो वीराकः आंबा-लींबाक-सोमदेवाश्च।
शील्रू-हीरलदुहिते जिनधर्मसदोद्यतेऽत्यंतम् ॥ १५ ॥

पासडभार्या**साजिणि**पुत्रौ द्वौ **विजयसिंह-नयणाकौ**।
वीरापत्नी**राजश्री**सूनुत्रयं तु **जगपालः** ॥ १६ ॥

हरपाल-देवपालौ आंबाभार्या च **ललतुका** श्रेष्ठा।
नरपालसुतश्चैको **लींबाक**स्याऽ-**णपमा**ख्या ॥ १७ ॥

विजयश्री-यशधरयोर्नरसिंहसूनुरतिथिजनभक्तः।
पाती दुहिता चैका कुटुंबमेतच्च सुविशालम् ॥ १८ ॥

श्री**भुवनरत्न**पूज्याः पारींद्रा वादिकुंजरे।
एकांतरा निर्वृतिका गच्छाधाराः शुभाचाराः ॥ १९ ॥

आनंदप्रभुसूरीन्द्रास्तत्पट्टांभोजभानवः ।
सिद्धान्तजलधिपारं प्रापुः प्रज्ञाप्रकर्षेण ॥ २० ॥
तत्पट्टे [सु]विशुद्धे श्रीमंतो **वीरदेव**सूरीन्द्राः ।
तत्पट्टे सच्चरिताः धीमंतः **कनकदेवा**ख्याः ॥ २१ ॥
ससुतो **गुणधर**श्राद्धः पार्श्वे श्री**कनकदेव**सूरीणाम् ।
धर्मोपदेशमतुलं शुश्रावेत्थमघापहम् ॥ २२ ॥
गुणानां सर्वेषां जगति जयिनी संपदनिशं
यया दोषाः सर्वे झगिति गुणतां यांति गृहिणाम्
न चेद्भाग्याद्दश्या जलधिजलकल्लोलचपला
सा केषांचिद्व्यसननिकरे धर्मकार्येऽ परेषाम् ॥ २३ ॥
जिनबिंबभवनपुस्तकतुर्यविधिसंघसप्तक्षेत्रेषु ।
यो वपति वित्तबीजं लभते हि परत्र स बहुफलं ॥ २४ ॥
[तत्र च] मुनिक्षेत्रांतर्विशेषपुण्याय पुस्तकक्षेत्रम् ।
पुस्तकलिखनप्रभावाद्भवंति धर्मोपदेष्टारः ॥ २५ ॥
कलिकालकालविलसिततमसा पिहिते च धर्मवररत्ने ।
श्रुतलिखितपुस्तकमये दीपे तत्प्रकटनं भविनाम् ॥ २६ ॥
केवलज्ञानपरिस्पर्द्धिश्रुतज्ञानमुदीरितिम् ।
अतस्तल्लेखने पुण्यमगण्यं गदितं जिनैः ॥ २७ ॥
इत्थं श्रुत्वा पुत्रसाहाय्यतोऽसौ श्रेष्ठी न्यायोपात्तवित्तेन हृद्यम् ।
शांतेर्वृत्तं लेखयामास शुद्धं पित्रोः श्रेयस्कारणं हर्षपूर्णः ॥ २८ ॥
अष्टत्रिंशत्तमवर्षे **पोसीनक**पुरे वरे ।
पुस्तकं वाचयामास गुरोः **कनकसूरि**तः ॥ २९ ॥
क्षेत्रज्ञानांकुराणां निबिडतमतमस्कांडचंडांशुबिंबं
....स्तापांबु[प्र]वाहः कुमतमयिमलासंगगंगाप्रवाहः ।
श्रेयः श्रीवश्यमंत्रः शिवपथपाथिकश्रेणिपीयूषसत्रं
दुःखार्त्ताद्वैतमिद्धं जयति जिनगिरां सारणिः पुस्तकोऽयम् ॥ ३० ॥
शुभं भवतु ॥ छ ॥

No. 203 : Munisuvrataswāmicaritramahākāvya-Padya

मुनिसुव्रतस्वामिचरित्रमहाकाव्य-पद्य

Folios – 193
Language – Sanskrit
Author – Muniratnasūri
Extent – Granthas 6806
Size – 33.5 × 2 inches
Condition – Good
Age of MS. – c. First half of 14th cent. V.S.
General Remarks – Folios 140, 142, 172 and 177 missing.

आदिः—

॥ ॐ नमः सर्वज्ञाय ॥

पायात् पदनखश्रेणिर्मणिस्वच्छा जिनस्य वः ।
धर्मस्य दशरूपस्य या क्रीडादर्पणायते ॥ १ ॥

पादाग्रजाग्रनिर्व्याजराजमौलिमणिद्युतिः ।
देवदेवः स वः पातु नवः श्रीवृषभध्वजः ॥ २ ॥

श्रीशांतेः शांतिकं पादाः स्फुरत्सौवस्तिकश्रियः ।
तन्वतां जगतां प्रेंखन्नखज्योतिर्जलप्लवैः ॥ ३ ॥

हरिवंशसरोनीलोत्पलश्रीः श्रीनिकेतनम् ।
देवेंद्रनेत्ररोलंबचुंबितः पातु सुव्रतः ॥ ४ ॥

उपास्ते यं क्षमाभारोद्धारवैमुख्यदुर्यशः ।
स्वस्यापनेतुं कूर्मेशस्तीर्थेशः सोऽस्तु वः श्रिये ॥ ५ ॥

यत्पादौ भक्तलोकानां द्वेधा दौर्गत्यवारणौ ।
निधी नव्याविवाशेषसुरासुरनिषेवितौ ॥ ६ ॥

आश्रितौ शंखमकरपद्मैस्तैर्निधिनिर्जितैः ।
लक्ष्मणच्छद्मना प्रेक्ष्य कच्छपोऽप्याश्रयद् ध्रुवम् ॥ ७ ॥

कल्याणकदलीकंदानुल्लासयतु वश्चिरम् ।
स्फुरत्तेजोघनच्छायः स श्रीमान् मुनिसुव्रतः ॥ ८ ॥ त्रिभिर्विशेषकम् ।

तरलोऽपि ततः किंचिच्चरित्रं निजशक्तितः ।
मुनिसुव्रतनाथस्य वक्ष्ये तद्भक्तिलुब्धधीः ॥ ९ ॥

अन्तः—

एतत्कुंडलवस्तुवर्णघटितं श्रीसुव्रतस्य प्रभो-
वृत्तं वृत्तमनोहरं दधति ये कर्णे सकर्णाश्चिरम् ।
चित्रं नात्र यदेककुंडलकला तेषां समुज्जृंभते
तच्चित्रं त्वनुरागजागरभुवः स्युर्यत्पुमर्थश्रियः ॥ ७७ ॥

उत्प्रेंखन्नखरत्नदीपमसितप्रौढांशुदूर्वांकुरं
नम्राखंडलमौलिमौक्तिकरुचि श्रीखंडपिंडस्थिति ।
श्रीर्नीराजनभाजनं क्रमयुगं चंचत्कटाक्षाक्षतं
बिभ्राणो मुनिसुव्रतस्य कुरुताद्वोऽनर्गलं मंगलम् ॥ ७८ ॥

निःसारोऽपि गिरां ममैष सुतरां गुंफस्त्रिलोकीपतेः
सारैः सच्चरितैर्युतः कृतधियामादृत्यतामेष्यति ।
मृत्पिंडश्चरणाहतिस्थितिरपि श्रीराजमुद्रांकितः
प्रीत्योल्लास्य महाधनैरिह जंनमौलौ न किं स्थाप्यते ॥ १८३ ॥

इत्याचार्यश्रीमुनिरत्नविराचिते श्रीमुनिसुव्रतचरिते महाकाव्ये अश्वावबोधस्कंदकाचार्यकार्त्तिकपथाविस्तारिविहारस्वामिनिर्वाणस्वरूपवर्णनस्त्रयोविंशः सर्गः ॥छ॥ ग्रं० १८५ । समाप्तं चेदं श्रीमुनिसुव्रतचरितम् ॥छ॥ मंगलं महाश्रीः ॥ शुभं भवतु लेखक[पाठकयोः] छ ॥ सर्वांक श्लोक ६८०६ ॥

*

No. 204 : Neminathacaritra (from Bhavabhāvanāvṛtti)
नेमिनाथचरित्र (भवभावनावृत्त्यन्तर्गत)

Folios – 276
Language – Prakrit
Author – Maladhārī Hemacandrācārya
Age of MS. – c. Beginning of 13th cent.V.S.
Extent – Gathas 5100
Size – 18.5 × 2.2 inches
Condition – Good
Date of Composition – 1170 V.S.

General Remarks – Though this itself is a part of the Svopajña Vṛtti of Bhavabhāvanāprakaraṇa, some additions are made at the beginning of the work in order to account for its being preserved as a separate work. In a manuscript of the same work, preserved in the Palm Leaf Jñānabhaṇḍāra established by the Kharatara Ācārya Śrījinabhadrasūri at Jesalmer, has even a Praśasti inserted in it.

No. 205 : Mahāvīracaritra : महावीरचरित्र

Folios – 169
Language – Prakrit
Author – Nemicandrasūri
Age of MS. – 1197 V.S.

Extent – Gāthās 2400 ; Granthas 3000
Size – 11·7 × 2 inches
Condition – Good
Date of Composition – 1141 V.S.

अन्तः—

इय एवं संखेवा **वीरजिणिंदस्स** साहियं चरियं ।
संपइ जेण णिबद्धं एत्तो एयं पवक्खामि ॥

सिरि **जंबुणामसिरिपभवसूरिसेज्जंभवाइसूरीणं** ।
परिवाडीए जाओ **चंदकुले वड्डगच्छंमि** ॥

सिरि**उज्जोयणसूरी** उत्तमगुणरयणभूसियसरीरो ।
वेहारुयमुणिसंताणगयणवरपुन्निमाइंदो ॥

सोमत्तणेण सोमं खमं खमाए य जो अभिक्खिवइ ।
थिरयाए मेरुगिरिं गंभीरत्तेण मयरनिहिं ॥

जंमि य गच्छे आसी सिरि**पज्जुन्ना**भिहाणसूरि त्ति ।
सिरि**माणदेवसूरी** सुपसिद्धो **देवसूरी** य ॥

उज्जोयणसूरिस्स उ सीसो अह **अम्बदेव**उज्झाओ ।
खममद्दवऽज्जवाईगुणकलिओ सोममुत्ती य ॥

तस्स विणेएण इमं **वीरजिणिंदस्स साहियं चरियं** ।
पावमलस्स खयट्ठाय सूरिणा **नेमिचंदेण** ॥

जं एत्थ अणागमियं लक्खणछंदेहिं दूसियं जं च ।
रइयमणाभोगेणं मिच्छामिह दुक्कडं तस्स ॥

जो पढइ इमं चरियं वक्खाणइ सुणइ वायए वा वि ।
वीरस्स उ भत्तीए सो पावइ परमकल्लाणं ॥

अणहिलवाडपुरंमी सिरि**कन्न**नराहिवंमि विजयंते ।
दोहट्टिकारियाए वसहीए संठिएणं च ॥

वाससयाणं एक्कारसस्स विक्कमनिवस्स विगयाणं ।
अगुयालीसे संवच्छरंमि एयं निबद्धं ति ॥ छ ॥

ग्रंथाग्रं श्लोकतो ज्ञेयं सहस्रात्रितयं त्विदम् ।
तिष्ठतः पुष्पदंतौ च यावत्ताव............ ॥

गाथा २४०० श्लोक ३०००। संवत् ११९७ आसोय वदि १० सोमे मघानक्षत्रे शुक्रयोगे च **महावीरचरितं** समाप्तम् ॥

*

No. 206 : Pārśvanāthacaritra : **पार्श्वनाथचरित्र**

Folios – 323
Language – Prakrit
Author – Devabhadrasūri
Size – 27.5 × 2.2 inches
Condition – Good
Date of Composition - 1168 V.S.
Age of MS. – c. First half of 13th Cent. V.S.
General Remarks – Folio 323 contains three very nice picture-decorations in black ink.

आदिः—

॥ ॐ नमो वीतरागाय ॥

धम्ममहामहिमुद्धरिउमिच्छुणो जस्स **विहियसत्तसिरो** ।
दाउं साहेज्जं पिव उवट्ठिओ सहइ भुयगवई ॥

तं पणयपूरियासं तिजयपयासं विमुक्कभववासं ।
पणमह जिणिंद**पासं** कयकमठासुरसिरीनासं ॥

तं चेव पुणो पणमह दुजीहसहसक्खयं भुयगसक्का ।
जस्स गुणत्थुइसुहपेहणेण मण्णंति कयकिच्चं ॥

नमह नमंतसुरासुरनरिंदमणिमउडपाडियपडिबिंबं ।
भुवणजणुद्धरणकए कयबहुरूवं व **उसभजिणं** ॥

निज्जियदुज्जयमयणा अमोहवयणा भयत्तजणसरणा ।
सिरि**अजियनाह**पमुहा सेसा वि जयंति जिणवसभा ॥

उत्तसियरसियविलसियवियसियचंकमियरमियरम्माहिं ।
जो संगमयप्पियाहिं न मोहिओ जयइ सो **वीरो** ॥

सिद्धंतो जयइ समुल्लसंतबहुभंगहेउदिट्ठंतो ।
फारफुरंतनिरंतरतरंगनिवहो समुद्दो व्व ॥

करकलियकमलसोरभमिलियालिरवच्छलेण कइवसहा ।
जं मग्गंति वरं पिव मणिच्छियं जयइ सा **वाणी** ॥

सिस्साण सिसूणं पिव विचित्तसत्थोसहीरसं दाउं ।
वइवित्थरं जणंता जयंति गुरुणो वि गुणगुरुणो ॥

अन्तः—

एवं च निव्वुइगए जिणनाहे गणहरप्पबंधे य ।
अड्ढाइयवरिससयाइं जाव तित्थं पवित्थरियं ॥

तो तिहुयणेक्कतिलओ मंगलनिलओ जिणो **महावीरो** ।
उप्पन्नो अच्छेरयभूयमहासत्तसंपन्नो ॥

तित्थम्मि वहंते तस्स भयवओ तियसवंदणिज्जम्मि ।
चंदकुलम्मि पसिद्धो विउलाए **वइरसाहाए** ॥

सिरि**वद्धमाण**सूरी अहेसि तवनाणचरणरयणनिही ।
जस्सऽज्ज वि सुमरंतो लोगो रोमंचमुव्वहइ ॥

स्सासि दोन्नि सीसा जयविक्खाया दिवायरससि व्व ।
आयरिय**जिणेसर**-**बुद्धिसागरा**यरियनामाणो ॥

तेसिं च पुणो जाया सीसा दो महियलम्मि सुपसिद्धा ।
जिणचंदसूरिनामो बीओऽ**भयदेव**सूरि त्ति ॥

सिद्धंतवित्तिविरयणपगरणउवयरियभव्वलोयाण ।
को ताण गुणलवं पि हु होज्ज समत्थो पवित्थरिउं ॥

तेसि विणेयस्स **पसन्नचंद**सूरिस्स सव्वगुणनिहिणो ।
पयपउमसेवगेहिं **सुमइ**उवज्झायसिस्सेहिं ॥

संवेगरंगसालाराहणसत्थं जगम्मि वित्थरियं ।
रइयं च **वीरचरियं** जेहिं **कहारयणकोसो** य ॥

सोवन्निडयमंडियमुणिसुव्वय-वीरभवणरमणीए ।
भरुयच्छे तेहिं ठिएहिं मंदिरे **आमदत्तस्स** ॥

सिरि**देवभद्दसूरी**हिं विरइयं **पासनाहचरियमिमं** ।
लिहियं पढमिल्लुयपोत्थयम्मि गणि**अमलचंदेण** ॥

इहइं जे उवयरिया मुणिगिहिणो ते सया वि नंदंतु ।
काराविय च एयं जेहिं ते पुण निसामेह ॥

जयपयडवियड**वायड**कुलमंदिरजयपडायपडितुल्लो ।
कप्पडवाणिज्जपुरे सेट्ठी **गोवद्धणो** आसि ॥

बावन्नसिहरमणहरसुवन्नवरकलससोहमाणसिरं ।
जिणवासुपुज्जभवणं जेणं काराविय तुंगं ॥

तस्स सुओ **सोड्ढा**कुच्छिसंभवो सेट्ठिजज्ज**णागो** त्ति ।
छत्तावल्लिनिवासी अहेसि सावयगुणाणुगओ ॥

तस्स सुया **सुंदरि**कुच्छिसंभवा **सिद्धसेट्ठि वीरो** य ।
अन्नो य भाइणेज्जो सुओ व्व **जसणाग**सेट्ठि त्ति ॥

जिणभवणबिंबपोत्थयसंघत्थसुतित्थजत्तकरणेण ।
नियजम्मजीवियाणं फलमुवलद्धं जए जेहिं ॥

अह हेममयं व विभूसणेहिं णेगेहिं सेट्ठि**वीरेण** ।
सिरि**पासनाह**बिंबं सुट्ठु पइट्ठावियं लट्ठं ॥

पित्तियसुय**गग्गय**सेट्ठि**आम**साहिएण परमरिद्धीए ।
काऊण तित्थजत्तं निव्विग्घं संघजुत्तेणं ॥

वीरसुएण य **जसदेव**सेट्ठिणा **नन्न**ठक्कुरेणं च ।
कारवियं सुहबोहं परमेसर**पासचरिय**मिमं ॥

काले वसुरसरुद्दे ११६८ वच्चंते विक्कमाओ सिद्धमिमं ।
अणुचियमिह सूरीहिं खमियव्वं सोहियव्वं च ॥

इय विमलकेवलाभोयलोइयालोयलोयभावस्स ।
बहुसत्थसमुद्धरिए **पासजिणिंदस्स वरचरिए** ॥

नेव्वाणलाभनामो विहुणियसव्वंगिवग्गसंतावो ।
पंचमओ पंचमओ समत्थिओ एस पत्थावो ॥

निप्पत्तिमुवगयमिमं **मुणिसुव्वयसामिणो** पसाएण ।
अंबा-सुदरिसणा-बंभसंति–सुयदेवयाणं च ॥

एयं तिलोयपहु**पासजिणेसरस्स** जे सुंदरं **चरिय**मेक्कमणा कहिंति ।
जे वा पढंति निसुणंति धरंति चित्ते भत्तिब्भरेक्कहियया सइ संथुणंति ॥

ते रोगसोगधणनासपवासवेरिभूयाइसंभवमहादुहविप्पमुक्का ।
भोत्तूण वंछियसुहाइं जणेण पुज्जा सज्जो लहंति सुरलोयसिरिं सिवं च ॥छ॥

मंगलमस्तु ॥ इति **श्रीप्रसन्नचंद्रसूरिपादसेवकदेवभद्राचार्यविरचितं पार्श्वनाथचरितं समाप्तम्** ॥ छ ॥ छ ॥

*

No. 207: Pārśvanāthacaritramahākāvya—Padya

पार्श्वनाथचरित्र महाकाव्य—पद्य

Folios – 187
Language – Sanskrit
Author – Māṇikyacandrasūri
Age of MS. – 14th cent V.S.

Extent – Granthas 5278
Size – 32 × 2·5 inches
Condition – Good
Date of Composition – 1276 V.S.

आदिः—

ॐ नमो विश्वमित्राय जैत्राय परमात्मने ।
लोकः कोक इवास्तोकप्रीतिः संपद्यते यतः ॥ १ ॥

ज्ञानरंगैकदेशेऽपि यस्य लोकत्रयी नटी ।
भावैरनन्तैर्नृत्यन्ती भाति पायाज्जिनः स वः ॥ २ ॥

अन्तः—

इत्याचार्यश्रीमाणिक्यचन्द्रविरचिते॰ महाकाव्ये श्रीपार्श्वनाथविहारनिर्वाणवर्णनो नाम दशमः सर्गः समाप्तः ॥ छ ॥

सद्वृत्तलक्ष्मीरचलप्रतिष्ठानिकेतनस्फारसरस्वतीकः ।
मनुष्यलोकप्रतिमः पृथिव्यां श्री**कोटिकः** स्फीतगणः समस्ति ॥ १ ॥

सदापिनाकिश्रितपादभूमेः कैलाशकान्तेरिह **वज्रसूरेः** ।
सदोषधीभेदविभासमाना **वज्राह्वया** सन्ततिचूलिकाऽस्ति ॥ २ ॥

अस्ताघलक्ष्मीसुभगंभविष्णुः कलाविलासिद्विजपुण्डरीकः ।
श्रीराजगच्छः शुचिमानसश्रीस्तत्रास्ति गच्छः पृथिवीपवित्रः ॥ ३ ॥

पुंसां विग्रहजं विकारमखिलं निर्मूलमुन्मूलयं-
स्तत्राद्यः समभूद्भवामयभिषक् **प्रद्युम्नसूरिर्गुरुः** ।
येन स्वेदयता प्रयुज्य तरलां तर्कोज्ज्वलां भारतीं
वादीन्द्राः प्रविलापिनो घनतरं दर्पज्वरं त्याजिता ॥ ४ ॥

दिगम्बरसमाक्रान्तावेकपट्टं समाददे ।
यः प्रत्यक्षं नरेन्द्रस्य जगतस्तद्यशः पुनः ॥ ५ ॥

तर्कग्रन्थविचारदुर्गमवनीसंचारपंचानन-
स्तत्पट्टेऽ**भयदेवसूरि**रजनि **श्वेतांबर**ग्रामणीः ।
सद्वाक्यश्रुतिलालसा मधुकरी कोलाहलाशंकिनी
हित्वा विष्टरपंकजं श्रितवती ब्राह्मी यदीयाननम् ॥ ६ ॥

द्वग्निम्नगाः सत्पथभेदमेता ध्रुवं करिष्यन्ति जडैः समेताः ।
इतीव रोधाय चकार तासां ग्रन्थं नवं **वादमहार्णवं** यः ॥ ७ ॥

विद्वन्मंडलमौलिमंडनमणिः प्रेंखत्तपोऽहर्म्मणि-
र्निर्ग्रंथोऽपि **जिनेश्वरः** समजनि श्रीमांस्ततः सद्गुरुः ।
यः स्फूर्जद्गुणपुंज**मुंज**जगतीजिष्णोः पुरः प्रश्निलान्
वादे वादिवरान् विजित्य विजयश्रीसंग्रहं संव्यधात् ॥ ८ ॥

तत्पट्टपूर्वपर्वतमण्डनमार्त्तण्डमण्डलश्रीकः ।
श्री**अजितसेन**सूरिर्भूरितमस्तोमहृज्जातः ॥ ९ ॥

तर्कग्रन्थपथप्रथापृथुमतिः क्ष्मापीठवाचस्पतिः
सूरिर्भूरिनयस्ततः समजनि श्री**वर्द्धमाना**ह्वयः ।
आस्थाने विदुषां यदीयवचनैरुत्कंटके वादिभि-
र्लेशेनापि भियेव नाम न पदोल्लापप्रयासः कृतः ॥ १० ॥

श्रीसिद्धान्तव्यवहृतिपटुस्तत्पदाम्भोजभृंगः
सूरिः श्रीमानजनि जगतीमंडनं **शीलभद्रः** ।
अंगोद्धृत्या सकलसुमनःसाक्षिकं दीयमाना-
ऽप्यस्तव्याजं यदमलवचःसंपदाप प्रवृद्धिम् ॥ ११ ॥

अतुच्छ**राजगच्छ**श्रीसमुल्लासनलालसः ।
सूरिः कृपांबुधिरभूत्तत्पदे **भरतेश्वरः** ॥ १२ ॥

द्राक्षे ! ख्यापय शक्तिमात्मविभवं पीयूष ! पोषं नय
प्रख्याता भव सर्करे ! तव मधो ! माधुर्यमस्तु स्फुटम् ।

खर्जूर ! प्रभव प्रपंचय रसं सत्काव्य ! येनाधुना
न श्रोत्राणि पवित्रयन्ति कृतिनामस्मद्गुरूणां गिरः ॥ १३ ॥
तत्पट्टपूर्णकलशाः श्रीवैरस्वामिसूरयो गुरवः ।
विकिरन्तु दुरितनिकरं वितरन्तु समीहितां सिद्धिम् ॥ १४ ॥
ज्योतिःशास्त्रमहर्निशं गणयतां नैमित्तिकान् पृच्छतां
चर्चां शाकुनिकैः समं कलयतां क्लेशो भवेत् केवलः ।
पूज्यानां यदि नाममंत्रकलनामैत्रीपवित्रीकृता
नो मिथ्या शृणुताऽऽप्नुवन्ति परमां ते कार्यसिद्धिं जनाः ॥ १५ ॥
षट्तर्कीललनाविलासवसतिश्चंचत्तपोऽहर्पति-
स्तत्पट्टोदयचन्द्रमाः समजनि श्रीनेमिचन्द्रप्रभुः ।
निःसामान्यगुणैर्भुवि प्रसृमरैः प्रालेयशैलोज्ज्वलै-
र्यैश्चक्रे कणभोजिनो मुनिपतेर्व्यर्थं मतं सर्वतः ॥ १६ ॥
यस्य श्रोत्रसुधाकिरः शुचिगिरः श्रीभारती शृण्वती
कामं कंपयति स्म विस्मयरसाकीर्णाऽपि न स्वं शिरः ।
मंदारप्रभृतिप्रभूतकुसुमस्रग्दामलीनालिनां
यद्वाणीश्रवणान्तरायजननः कोलाहलः खेलति ॥ १७ ॥
यत्र प्रातिभशालिनामपि नृणां संचारमातन्वतां
संदेहैः प्रतिभाकिरीटपटली सद्यः समुत्सार्यते ।
नीरंध्रं विषमप्रमेयविटपिव्रातावकीर्णे सदा
तस्मिंस्तर्कपथे यथेष्टगमना जज्ञे यदीया मतिः ॥ १८ ॥
शिष्यस्तस्य प्रशस्यः समजनि जगदानन्दकंदाम्बुदश्रीः
सूरिः श्रीसागरेन्दुर्वचनरसभरैर्यस्य सिक्तां जनौघः ।
रोमोद्भेदांकुराढ्यां शिरसि युतकरांभोजपत्रां प्रमोदा-
दस्रांभोबिंदुपुष्पां सुकृतफलवतीं कायवल्लीं बिभर्त्ति ॥ १९ ॥
निर्व्याजं घनदानयोग्यजडतावस्त्वन्विता मन्मति-
र्यत्पादप्रभवप्रसादविलसत्पद्याक्षरैः स्वीकृतैः ।

संदेहोल्बणशौल्किकैः प्रतिपदं बाधामनासादिता
ग्रन्थालीपथकान्तराणि परितः स्पष्टं समुल्लंघते ॥ २० ॥

गुरुप्रसादविगलज्जाडिमैकतमस्तमः ।
सूरिर्**माणिक्यचंद्रो**ऽभूत्तत्पादाब्जमधुव्रतः ॥ २१ ॥

वंशः सत्त्वगुरुस्थितिः समहिमा सद्धर्मकर्मोदया-
दस्ति स्वस्तिनिबंधनं मतिमतां श्री**भिल्लमालाह्वयः** ।
आमूलं भुवनाद्भुतैकगुणभूः श्री**मेहिल**स्यांगजो
वीरस्तत्र पवित्रवृत्तसदनं मुक्ताफलश्रीरभूत् ॥ २२ ॥

विमलमतिमृणालिनीमरालः सकलकलाकमलावलीविवस्वान् ।
निरुपममहिमाहिमावनीभृत् समजनि सूनुरमुष्य **वर्द्धमानः** ॥ २३ ॥

कुमारपालक्ष्मापाला**जयपाल**महीभुजोः ।
यः सभाभूषणं चित्रं जैनं मतमरोचयत् ॥ २४ ॥

त्रिभुवनपालः श्रीमान् **मल्हः** सचक्रनंदकः ।
प्रियसत्यः श्री**देहड** इत्याख्याः पुरुषोत्तमाः ॥ २५ ॥

सतीसीमंतमाणिक्य**श्रीमाढू**कुक्षिसंभवाः ।
सच्चरित्रास्त्रयः पुत्रास्तस्य शस्यधियोऽभवन् ॥ २६ ॥

प्रज्ञावता सत्कविपुंगवेन श्री**पल्हणे**नाऽऽत्मसुतेन साकम् ।
माणिक्यसूरिं गुरुमन्यदेति श्री**देहडो**ऽजल्पदनल्पभक्तिः ॥ २६ ॥

नीरागतानिधी **राजगच्छ**भूर्गुणवारिधिः ।
सूरिः **प्रद्युम्नसूर्या**ख्यः पूर्वं वः पूर्वजोऽभवत् ॥ २७ ॥

सपादलक्षगोपाल**त्रिभुवनगिर्या**दिदेशगोपालान् ।
यश्चतुरधिकाशीत्या वादजयै रंजयामास ॥ २८ ॥

श्री**अभयदेवसूरि**स्तच्छिष्यस्तर्कभूरभूत् ।
भग्नासनाऽलितुमुलाद् गीर्यदास्यमशिश्रियत् ॥ २९ ॥

जडोल्लासेन सन्मार्गभेदिनी दृक्तरंगिणी ।
रोद्धुं चकार स नवं ग्रंथं **वादमहार्णव**म् ॥ ३० ॥

तदाम्नायजुषां युष्मादृशानामपि युज्यताम् ।
सद्ग्रंथकरणे स्फीतपरोपकरणे मतिः ॥ ३१ ॥

माणिक्यचंद्राचार्येण तस्येति प्रार्थनावशात् ।
श्री पार्श्वनाथचरितं वाचां पथि विपंचितम् ॥ ३२ ॥

गगनवसनमाशायंत्रगं शीतरोचिःसितकुमिजगुलुंछादात्तरुक्तंतुजालैः ।
विरचयति विरिंचिर्यावदुल्लासिताराकुसुमकमिह शास्त्रं नंदतात्तावदेतत् ॥ ३३ ॥

तमो विघटयन्नलिप्रतिममम्बरारामतः सदा दिनमुखे निशाविकसदृक्षपुष्पोत्करम् ।
करैः किरणमालिकश्चुटति यावदुल्लासिभिर्मतं जिनपतेर्मतं जयतु तावदेतत्
क्षितौ ॥ ३४ ॥

श्रीसंघेन मयि क्रमांबुजरजःकल्पे पयःकल्पया
दृष्ट्यावाप इव प्रसादविटपी न्यस्तः परं पुष्यताम् ।
यस्माद्विश्वजनानुरागमहिमश्रीमंजरीसद्यशः-
पुष्पोल्लासि परोपकारकरणैश्वर्यं फलं चाप्यते ॥ ३५ ॥

रसर्षिरवि १२७६ संख्यायां समायां दीपपर्वणि ।
समर्थितमिदं वेलाकूले श्रीवटकूपके ॥ ३६ ॥ छ ॥ ग्रन्थाग्रं ५२७८ ॥

अष्टसप्तत्यधिकशतद्वयोपेतपंचसहस्राः ॥ छ ॥ मंगलमस्तु लेखकपाठकयोः ॥ छ ॥

॥ ॐ नमः श्रीपार्श्वनाथाय ॥

यत्राऽनेकबुधा अनेककवयो धिष्ण्यानि भूयांस्यलं
चन्द्रस्योपचयः कलंकविकलः संजायते सर्वदा ।
वक्रः कोऽपि न दृश्यते न च गुरुर्मित्रोदये निष्प्रभः
पल्लीपालजनान्वयो नवनभोलक्ष्मीं दधानोऽस्ति सः ॥ १ ॥

तत्रोल्लासितलोकभूरिकमलः श्लिष्यत्प्रतापाकृती
राज्ञो मंडलवृद्धिकारणतया प्रीतिं समुत्पादयन् ।
दोषातिक्रमजातकान्तिसुभगो बिभ्रत्सुवृत्तां तनुं
मार्त्तंडो जसडूर्धनी समभवन्नंदाणिपूर्मंडनम् ॥ २ ॥

तद्भार्या योषितां वर्या परिचर्यापरायणा ।
जिनेशचरणद्वन्द्वे शोभना **शोभना**ऽजनि ॥ ३ ॥

महाव्रतानीव सुताः स्युस्ताभ्यां पंच विश्रुताः ।
गुप्तित्रयमिवानिंद्यं पुत्रीत्रयं च जज्ञिरे ॥ ४ ॥

तेषां च ज्येष्ठः किल **पूर्णचन्द्रो** धर्मानुरक्तो **यशश्चन्द्र**नामा ।
औचित्यचर्याचतुरस्त्व**आभडो नाहड**जाल्हणश्च तथा परे ॥ ५ ॥

शीलमती च **सहजू रत्नी** च श्रावकव्रतम् ।
श्री**यशोभद्र**सूरीणां चरणांते प्रपेदिरे ॥ ६ ॥

केल्हणाल्हणरत्नाश्च राजपालश्चतुर्थकः ।
पूर्णस्यागण्यपुण्यस्य तनयाः सुनया अमी ॥ ७ ॥

केल्हणाल्हणरत्नानां सुताः संति यथाक्रमम् ।
अजयोऽथारिसिंहश्च गुरुदेवार्च्चने रतो ॥ ८ ॥

सुगणः सुवर्णशाली बिभ्राणो नैव गुरुगणाक्रमणम्
सुकवेः श्लोक इव स्तनंधयास्ति**हुणपालो**ऽभूत् ॥ ९ ॥

यशश्चन्द्राज्जगद्देवोऽभूत्ततोऽपि **वरदेवः** ।
आभडः श्रीमानतुंगचरणांभोजषट्पदः ॥ १० ॥

आभडस्य सुता एतेऽ**भयश्री**कुक्षिसंभवाः ।
पांडवा इव विख्याताश्चित्रं कौरवसंगताः ॥ ११ ॥

प्रथमः **पद्मसिंहा**ख्यो **वीरचंद्रो** द्वितियिकः ।
आसलो मूलदेवश्च **देदल**श्चाथ पंचमः ॥ १२ ॥

चतुरश्चतुरो बिभ्रत् पुरुषार्थान् नयानिव ।
बभूव **नाहड**स्तुर्यो **नाउका** तस्य गेहिनी ॥ १३ ॥

मुक्तिमार्गा इव श्लाघ्या जज्ञिरे नंदनास्तयोः ।
त्रयोऽपि विशदाचाराः पितुराज्ञाविधायिनः ॥ १४

आद्यस्तेषां तु **शोभा**ख्यः पुत्रत्रयविराजितः ।
— —**आसड**नामा स्तत्रकीदृशः ॥ १५

स्फटिकनिर्मले यस्य मानसे सद्गुणांबुजे ।
राजहंसा इवाजस्रं वसंति परमेष्ठिनः ॥ १६ ॥

जिनसमयसुधाजलधौ सततं श्रुतदेवतेव रममाणा ।
आसमतीत्यभिधाना दयिता तस्यास्ति शीलवती ॥ १७ ॥

जनकोऽजायत तस्या धीमान् ।
यशोमतीति च माता विजू इत्यस्त्यपराभिधा ॥ १८ ॥

अभूच्च **पार्श्ववीरा**ख्यस्तनुजो धर्मवत्सलः ।
द्वितीयस्तु **पार्श्वचन्द्रः** स्वकुलाम्भोधिचन्द्रमाः ॥ १९ ॥

विनीता शीलसंपन्ना धर्मवेत्ता प्रियंवदा ।
मोही खेतू जयतुका च पुत्र्यस्ताभ्यामनिंदिता ॥ २० ॥

.... ।
.... ॥ २१ ॥

अथैकदा गुणाढ्यानां गुरूणां धर्मदेशनाम् ।
शुश्राव जनन्या सार्द्धं ज्ञानदानप्रकाशिकाम् ॥ २२ ॥

पार्श्ववीरस्तु चरितं लेखयामास पुस्तके ।
स्वपित्रोः श्रेयसे नव्यं सुकृती मंगलप्रदम् ॥ २३ ॥

श्रीपार्श्वनाथचरितं पार्श्ववीरेण धीमता ।
श्रीधर्मघोषसूरीणां दत्तं व्यालेख्य सद्भक्त्या ॥ २४ ॥

तथा च—

दिक्सोपानयुते द्युपल्वलतटे लोकांतपालावृते
तारापद्मचयेऽत्रिनेत्रजनकस्थानस्थलीराजिते ।
यावद् व्योमनि द्युतिजलं प्रोदंचति स्वेच्छया
तावन्नंदतु पुस्तिकोऽयमनघः पापठ्य........ ॥ २५ ॥

श्रीपार्श्वनाथचरितं श्रीधर्मघोषसूरयः श्रीपार्श्ववीरश्च चिरं नंदताम् । शुभं संघस्य ॥ छ ॥

*

No. 208 : Amamaswāmicaritramahākāvya—Padya

अममस्वामिचरित्रमहाकाव्य—पद्य

Folios – 282
Language – Sanskrit
Author – Muniratnasūri

Extent – Granthas 10,000
Size – 27·2 X 2·5 inches
Condition – Good

Age of MS. – c. Latter half of 13th cent. V.S. Date of Composition – 1252 V.S.
General Remarks – First two folios and last three folios are torn on one side.

आदिः—

॥ अर्हं ॥ भव्यांबुजन्मनां गोभिर्बोधलक्ष्मीप्रदाः सदा ।
सर्वक्षेत्रेषु युगपज्जिनादित्याः पुनंतु वः ॥ १ ॥

सुखयतु स जिनो यदंसदेशद्वयवसतिः पृथुसंहतिर्जटानाम् ।
मृगमदलिखितेव पत्रलेखाविरतिव विरेजे ॥ २ ॥

श्री**शांत**ये नमस्तस्मै राज्यवत् संयमेऽपि यम् ।
सुवर्णवारिजव्याजादन्वयुर्निधयो नव ॥ ३ ॥

सदानवानंदकरः शंखचक्रांकितक्रमः ।
देयादिष्टां श्रियं **नेमि**र्नवीनः पुरुषोत्तमः ॥ ४ ॥

श्रीपार्श्वः स जिनो जीयाद्यस्य दैत्यजयोत्सवे ।
चित्रं जैत्रं फणच्छत्रं फणींद्रः स्वयमुद्दधे ॥ ५ ॥

अंतर्वैरिवारवीरः स श्री**वीरजिनः** श्रिये ।
यत्सिंहनादः प्रत्यूहव्यूहाभिद्वल्गु वल्गति ॥ ६ ॥

श्रीसद्म **पद्मनाभ**स्य पादपद्मद्वयं स्तुमः ।
यद्यावन्नीयते चित्रमिंद्रैर्मूर्द्धावतंसताम् ॥ ७ ॥

द्वादशोऽतिद्वादशार्कतेजास्तेजांसि वः सदा ।
तन्यादन्यातिशायीति सममोऽप्य**ममो** जिनः ॥ ८ ॥

मुनींद्रवंदनानत्याप्यर्जितात्युन्नतश्रिये ।
ए........कृते श्रीम**दमम**स्वामिने नमः ॥ ९ ॥

जयति नवकेतकोदरदलावदातद्युति**गिरांदेवी** ।
कविहृदयवार्द्धिसंवासलग्नघनफेनपटलेव ॥ १० ॥

श्रीजिनालंकृतः शश्वत्सारसारस्वतप्रसूः ।
जीयाद्गिरींद्रैरक्षोभ्यो नवः **सिद्धांतवारिधिः** ॥ ११ ॥

श्रीगुरुभ्योनमस्तेभ्यो येभ्यो विद्याश्चतुर्दश ।
अमंदरागैर्म प्यंते रत्नवत् सदा ॥ १२ ॥

स्तौमि श्री**गौतम**ादींस्तानेकादश महाकवीन् ।
यैरपूरि द्वादशांगैः समस्या त्रिपदी गुरोः ॥ १३ ॥

शय्यंभवोऽस्तु वो भूत्यै चक्रे सर्वांगमूर्तिभृत् ।
येन दुःप्रसभाचार्यकालिकं **दशकालिकम्** ॥ १४ ॥

श्रीभद्रबाहुर्वः प्रीत्यै सूरिः शौरिरिवास्तु सः ।
यस्माद्दशानां जन्माऽऽसीन्निर्युक्ती नामृ............ ॥ १५ ॥

वाक्यैर्विशेषातिशयैर्विश्वसंदेहहारिभिः ।
जिनमुद्रं **जिनभद्रं** किं **क्षमाश्रमणं** स्तुवे ॥ १६ ॥

उमास्वातेर्वाचकस्य वाचः कस्य न चेतसि ।
ध्वनंत्यद्यापि घंटावत्तारटंकारसुंदराः ॥ १७ ॥

उदितोऽर्हन्मतव्योम्नि **सिद्धसेनदिवाकरः** ।
चित्रं गोभिः क्षितौ जह्रे कविराजबुधप्रभाः ॥ १८ ॥

स्तौमि श्री**हरिभद्रं**   र्हद्गीर्महत्तरा ।
चतुर्दशप्रकरणशत्याऽगोप्यत मातृवत् ॥ १९ ॥

व्योम्नश्च **भद्रकीर्त्ते**श्च प्रेंखत्तारागणस्य कः ।
बहुधामराजमित्राराद्धस्यावैतु वैभवम् ॥ २० ॥

अद्याप्यु**पमितिग्रंथ**च्छलाद्यज्जयडिंडिमः ।
विश्वे ध्वनत्यसौ जीयात् **सिद्धर्षिः** कविकुंजरः ॥ २१ ॥

पालित्तसूरिः स श्रीमान् अपूर्वः श्रुतसागरः ।
यस्मा**त्तरंगवत्याख्यकथा**श्रोतो विनिर्ययौ ॥ २२ ॥

मानतुंग-देवभद्रसूरी स्तुत्यौ मरालवत् ।
ऊषतुर्मानसे यौ श्री**शातवाहन-भोजयोः** ॥ २३ ॥

गुरुर्गूर्जरराजस्य चातुर्विद्यैकसृष्टिकृत् ।
त्रिषष्टिनरसद्वृत्तकविर्वाचां न गोचरः ॥ २४ ॥

गोभिर्दर्शनशुद्धिं योऽकषायस्वादुभिर्व्यधात् ।
सोऽपूर्वाभ्युदयः श्रीमान्नंद्या**च्चन्द्रप्र**[भः प्रभुः] ॥ २५ ॥

चैत्रवद् **धनपालो** न कस्य राजप्रियः प्रियः ।
सत्कर्णाभरणी यस्माज्जज्ञे **तिलकमंजरी** ॥ २६ ॥

जयंतु सूरयोऽन्येऽपि येषां वाग्ब्रह्मवैभवम् ।
ग्रंथसृष्टौ महाकाव्यसर्गेषु च नवं नवम् ॥ २७ ॥

वंद्यास्ते रामवत् संतो यैर्व्यस्तपरदूषणैः ।
क्रियते विबुधैः सेव्या निष्कलंका कृतिः कवेः ॥ २८ ॥

नरोत्तमः स वैकुंठः — — रातिश्च शंकरः ।
धाता पद्मासनस्तस्मात् समानः केन सज्जनः ॥ २९ ॥

वृत्तरम्येण पीयूषवर्षिणा सत्कलावता ।
नेंदुनाऽपि समः साधुः कालकूटसजन्मना ॥ ३० ॥

अनेकपस्य भद्रस्य गर्जतश्च स्थिरैः पदैः ।
साधोः कुर्यात् सुवंशस्य किं श्वेव पिशुनो भषन् ॥ ३१ ॥

अन्तः—

ख्यातस्याममसंज्ञया जिनभवे **कृष्णस्य** तद्वप्तुर-
प्येतन्मूलहरेः कुलस्य च कथां ग्रंथस्य लक्ष्मेण याम् ।
ग्रथ्नाति स्म स **भद्रबाहु**गणभृन्माति स्म साब्धेः समा
यन्नावीव कृतौ ममेह महिमा श्री**पार्श्वनाथस्य** सः ॥ ३८ ॥

उत्प्रेंखन्नखरत्नदीपमसितप्रौढांशुदूर्वांकुरं
नम्राखंडलमौलिमौक्तिकरुचि श्रीखंडपिंडस्थिति ।
श्रीनीराजनभाजनं क्रमयुगं चंचत्कटाक्षाऽक्षतं
श्री**पार्श्व**स्य दधत्यनर्गलमलं पुष्णातु वो मंगलम् ॥ ३९ ॥

अममचरिते भाविन्येवं तयोः सहजन्मनो-
र्जिननृपतया षष्ठो भावी भवः शिवशर्मवान् ।
तदनुचरयोः सीरिश्रीशार्ङ्गिणो— — —भवः
किमपि कथितः स्वाहा श्रोत्रद्वयाय मया सताम् ॥ ४० ॥

इत्याचार्यश्री**मुनिरत्न**विरचिते **महाकाव्ये** श्री**अममस्वामिचरिते** भाविश्रीअममस्वामि-संघादिसंख्यानिर्वाणमहोत्सवतद्भ्रातृबलदेवजीवनिर्वाणतत्समयभाविविष्णुबलदेवस्वरूपवर्णनो

विंशः सर्गः ॥ छ ॥ **संपूर्णं चेदं श्रीअममस्वामिचरितं महाकाव्यम्** ॥ ग्रंथाग्रं १५१ ॥

अपूर्वा यस्य पूर्वेयं चतुर्वर्णमनोहरा ।
चकास्ति क्ष्माशिलापट्टे श्री**वीरः** सोऽस्तु वः श्रिये ॥ १ ॥

जयतात्तत्पंचमगणनायकसंताननंदनप्रभवात् ।
कोटिकगणकल्पद्रोः प्रसृता श्री**वज्र**मुनिशाखा ॥ २ ॥

अतुच्छः पुष्पगुच्छश्री**श्चंद्र**गच्छस्तदुद्भवः ।
नंद्यात् सौरभ्यसंलुभ्यत्साधुरोलंबचुं– – ॥ ३ ॥

श्रीमां**श्चंद्रप्रभः** सूरिस्तस्माद्वार्धेरिवोदगात् ।
चक्रे कलाभिर्यः पूर्णः पूर्णिमां प्रकटां जनः(ने) ॥ ४ ॥

सूरिः श्री**धर्मघोषो**ऽभूत्तत्पट्टे देवताकृतिः ।
सिद्धराजस्तुतः कर्त्ता स्वमूर्त्तेः सूरिविंशतेः ॥ ५ ॥

निष्ठामतीतविषयामपि वर्त्तमाने व्युत्पादयन् विरचयन् गुणवत्सु वृद्धिम् ।
सूत्रार्थयुक्तिकलनासुविशुद्धबुद्धिर्यः शब्दसिद्धिमक – – – – –कारम् ॥६॥

तेन स्वगच्छे प्राधान्यं दत्त्वाचार्यपदे स्वयम् ।
प्रतिष्ठितः श्री**समुद्रघोष**सूरिरजायत ॥ ७ ॥

यो **मालवो**पात्तविशिष्टतर्कविद्योऽनवद्योपशमप्रधानः ।
विद्वज्जनालिश्रितपादपद्मः केषां न विद्यागुरुतामधत्त ॥ ८ ॥

धारायां नरवर्मदेवनृपतिं श्री**गोह्लद**क्ष्मापतिं
श्रीमत्**सिद्धपतिं** च **गूर्जरपुरे** विद्वज्जने साक्षिणि ।
स्वैर्यो रंजयति स्म सद्गुणगणैर्विद्यानवद्याशयो
लब्धीः प्राक्तनगौतमादिगणभृत्संवादिनीर्धारयन् ॥ ९ ॥

मुख्यस्तदीयशिष्येषु कवींद्रेषु बुधेषु च ।
सूरिः **सूरप्रभः** श्रीमान**वंती**ख्यातसद्गुणः ॥ १० ॥

दुर्वादिकैरवकुले ददताऽस्य मुद्रामन्वर्थतां गमयता निजमत्र नाम ।
गोभिर्न भव्यकमलाकर एव बोधं सचक्रपर्षदपि हर्षमलंभि येन ॥ ११ ॥

अथापरः श्री**मुनिरत्नसूरि**नामा निकामाद्भुतमूर्त्तिकीर्त्तिः ।
कैः पौनरुक्त्येन न यद्गुणौघः श्लाघाचलन्मौलिभिरभ्यवर्णि ॥ १२ ॥

सिद्धांतसाहित्यपदप्रमाणस्कंधत्रयज्योतिषशास्त्ररूपान् ।
सप्तापि वार्द्धीन् भजतो यदीये स्पर्द्धानुबंधादिव बुद्धिकीर्त्ती ॥ १३ ॥

तार्त्तीयिकः श्री**तिलकचंद्र**सूरिरजायत ।
सूरिस्तिलकयामास नभोयुद्बुद्धिनिर्जितः ॥ १४ ॥

पट्टे स्वे **जिनसिंह**सूरिसुगुरुं **सूरप्रभ**स्य प्रभोः
पट्टे किं च **जिनेश्वरा**भिधगुरुं संस्थाप्य मध्ये तयोः ।
आसीनो **मुनिरत्नसूरि**गणभृद्रेजे जगन्नंदिनो-
मेरुः सूर्यशशांकयोरिव लसज्जात्याश्वयोर्वा रथः ॥ १५ ॥

इतश्च—

वाराहीं नगरीं तनूमिव शुचिर्मुक्तोपमो भूषयन्
श्री**श्रीमाल**कुले **यशोधवल** इत्यासीत् स कोशाधिपः ।
निश्छिद्रोऽपि गुणान्वितस्ततलसत्तेजाः सुवृत्ताग्रणी-
र्यश्चौ**लुक्यपुर**श्रियो विहितवान् सीमंतशृंगारणम् ॥ १६ ॥

तत्सूनुर्द्धिषणानिरस्तधिषणारंभोऽस्ति दंभोज्झित-
स्त्रैविद्यो विदुषां स्थितो धुरि **जगद्देवो** नृदेवार्चितः ।
बालत्वे स्वकवित्वरंजितहृदः श्री**हेमसूरे**र्मुखा-
द्वैतीयीकमवाप बालकविरित्युद्दामसन्नाम यः ॥ १७ ॥

प्राक् चक्रे किल **धर्मघोष**गणभृद्यान् षोडश श्रावकान्
गच्छे स्वे व्रतिनां जिनागमविधिं व्यालुंपतां शासकान् ।
धर्मस्थायविशारदो नयपटुर्विद्याब्धिपारंगम-
स्तेष्वप्येष ययावशेषविबुधानुलंघ्य वाग्मुख्यताम् ॥ १८ ॥

यत्प्रश्नाशंकया शंके सरस्वत्यपि पुस्तकम् ।
हस्ते यत् सर्वदा धत्ते तत् सूरीणां कथैव का ॥ १९ ॥

आचार्याः कति नाम नामरगुरुस्पार्द्धिष्णवः प्रज्ञया
विद्यंते प्रभु**धर्मघोषगणभृद्गच्छे** गुणैरुल्वणैः ।

किंतु श्री**मुनिरत्नसूरि**सुगुरोर्वृत्तैरुदात्तैर्द्विधा
चेतः केतकसौरभैर्भ्रमरवद्यस्याध्यवास्यद्भुतम् ॥ २० ॥

श्री**रुद्रस्य कुमारभूपति**महामौहूर्त्तिकस्यात्मजो
मंत्री **निर्नय** इत्युदात्तचरितो विप्रोऽपि सुश्राद्धवत् ।

भट्टः **भूदन**संज्ञितश्च सुगुरोस्तस्यैव बोधाद्व्यधात्
सार्द्धं येन जिनेंद्रशासनघनौन्नत्यं धनस्य व्ययात् ॥ २१ ॥

मंत्रिणा बालकविना विद्वज्जनसभे स्थितः ।
प्रार्थ्यत श्री**मुनिरत्न**सूरिस्तेनान्यदा मुदा ॥ २२ ॥ चतुर्भिः कलापकम् ।

विद्यावल्लिफलं कवित्वमथ यद्वक्तृत्वमाहुर्बुधाः
पार्षद्यैर्**नरवर्मदेव**नृपतेः श्री**उज्जयिन्यां पुरि** ।

तद्विद्या**शिव**वादिनः किल **महाकाला**ग्रतो निर्जयो
यौष्माकं गुरुसाक्षिकं परिमलाप्लुष्टैर्मुहुस्तुष्टुवे ॥ २३ ॥

श्री**नेमि**ना **यदुकुलाधिपतिर्मुकुंदो** भावी जिनोऽस्ति कथितो**ऽमम**संज्ञया यः ।
कृत्वा नवं चरितमस्य सदस्यसाक्ष्यं व्याख्याय तत्फलयुगं मम दत्त
पूज्याः ॥ २४ ॥ युग्मम् ।

इत्यर्थितो मंत्रिवरेण भक्त्या ते**नाममस्वामि**जिनेश्वरस्य ।
भविष्यतश्चारुरसैः पवित्रं संपल्लताचैत्रसमं चरित्रम् ॥ २५ ॥

समुद्रसूरेश्चरणैकरेणुः समग्रविद्यासरसीकरेणुः ।
स्वान्योपकृत्यै श्रुतरत्नभूरि विनिर्ममे श्री**मुनिरत्नसूरिः** ॥ २६ ॥ युग्मम् ।

स्वयं भगवता तेन जैनान् विद्वज्जनान् प्रति ।
अभ्यर्थनेयं विदधे विबुधेश्वरचित्रकृत् ॥ २७ ॥

विद्वांसः सकलश्रुतार्णवनवागस्त्याः स्वमध्यस्थता-
प्रख्याताः सहृदः परिश्रमविदो युष्मासु बद्धोऽञ्जलिः ।

यद्विद्यासु विरुद्धमागमगमासिद्धं निबद्धं मया
ग्रंथेऽस्मिंस्तदिदं विशोध्यमधिकं कृत्वा प्रसन्नं मनः ॥ २७ ॥

गूर्जरवंशोद्योतन**पुत्रोदयराज**मंत्रितनुजन्मा ।
विद्वान् **सागरचंद्रः** प्रथमादर्शं लिलेखाऽस्य ॥ २८ ॥

एतद्विक्रमतो द्विपंचदिनकृद्वर्षे १२५२ कृतं **पत्तने**
सम्यक्शोधितवान् नृपाक्षपटलाध्यक्षः **कुमारः** कविः ।
सद्वैयाकरणाग्रणीर्विधिरुचिः श्री**पूर्णपालो यशः-**
पालो बालकविस्तथाऽऽ**मणमहानंदौ** च सभ्याग्रिमौ ॥ २९ ॥
श्री**शांतिमुनिरत्न**सूरि[सु]गुरून् व्याख्यापयन्मंदिरे
तस्मिन्नेव पुरे महर्द्धिकसभे संलेख्य तत्पुस्तके ।
मंत्री **बालकवि**र्विधाप्य च घनैरर्थव्ययैरुत्सवान्
प्रीतः कौतुकमार्ज्जयज्जयमयः कल्याणकोटिश्रियः ॥ ३० ॥
यावत्तीर्थेशकीर्त्तिस्त्रिभुवनभवनोत्संगरंगे नटंत्याः
सर्वाशादेवतास्ताः सलिलनिधिमहामर्दलान् वादयंति ।
व्योमश्रीश्चार्कचंद्रौ कलयति सततं तालवत्तावदेष
ग्रंथः प्राबोधिकश्रीर्जनयतु कृतिनां मंगलान्युज्ज्वलानि ॥ ३१ ॥
मंत्री **बालकविः** सदा — — नंदी चिरं नंदता-
द्दोषानुच्चपदस्थितो हरति यो लग्नेषु दत्ते श्रियम् ।
चित्रं साभ्युदयो जयोत्सवकरो यत्संमुखो यत्पुन-
स्त्रेधा श्री**मुनिरत्नसू**रिसुगुरौ लीनस्तदत्यद्भुतम् ॥ ३२ ॥
विद्यासु यः श्री**मुनिरत्न**सूरिगुरुप्रसादेन मनागधीती ।
स निर्ममे सूरिषु लब्धरेखः प्रशस्तिमेतां **जिनसिंहसूरिः** ॥ ३३ ॥ छ॥
इति प्रशस्तिः ॥ छ ॥ छ ॥ मंगलं महाश्रीः ग्रंथाग्रं[........]

*

No. 209 : Vasudevahiṇḍī Part I

वसुदेवहिंडी—प्रथम खंड

Folios – 308 Extent – Granthas 11200
Language – Prakrit Size – 32.5 × 2.2 inches
Author – Saṅghadāsagaṇivācaka Condition – Good
Age of MS. – c. Latter half of 14th Cent. V.S.
General Remarks – Folios 192, 269-272, 274-280, 282-289, 304 and 307 missing.

आदिः—

॥ ॐ ॥ नमो वीतरागाय ॥

णमो विणयपणयसुरिंदविंदवंदियकमारविंदाणं अरिहंताणं ।

णमो परिसुद्धणाणदंसणसमिद्धाणं सिद्धाणं ।

नमो जिणप्पणीयायारविहिवियक्खणाणं आयरियाणं ।

णमो सीसगणपरमसुयसंपयज्झावयाणं उवज्झायाणं ।

णमो सिद्धिवसहिगमणकारणजोगसाहणाणं साहूणं ।

एवं पंचणमोक्कारपरममंगलबलविवड्ढिउच्छाहो अणुओगधरे सिरसा पणमिऊण विण्णवेमि अणुजाणंतु मं गुरुपरंपरागयं **वसुदेवचरियं** णाम. संगहं वन्नइस्सं । तत्थ इमे अहिगारा । तं जहा कधुप्पत्ती पेढिया मुहं पडिमुहं सरीरं उवसंहारो तत्थ ताव **सुहम्मसामिणा जंबुणामस्स पढमाणुओगे** तित्थयरचक्कवट्टिदसारवंसपन्नवणागयं **वसुदेव-चरियं** कहियं ति तस्सेव पभवो कहेयव्वो । तप्पभवस्स य **पभवस्स** त्ति ।

अन्तः—

एवं पुव्वविवत्थियं जो एयं धणुं सजीवं करेइ तस्स एसा दारिया दायव्वा ॥ छ ॥ **समाप्तं प्रथमखंडं** ॥ छ ॥ ग्रंथाग्रं ११२०० मंगलमस्तु ॥ साहुरतनसीह-**कुम्वरसीहाभ्यां वसुदेवहिंडीपुस्तकं** लिखापितम् ॥

*

No. 210 : Vasudevahiṇḍī—Part I

वसुदेवहिंडी—प्रथम खंड

Folios – 243
Language – Prakrit
Author – Saṅghadāsagaṇivācaka
Age of MS. – 1388 V.S.
Extent – Granthas 11200
Size – 32.2 × 2.2 inches
Condition – Good

आदिः—

॥ ॐ नमो वीतरागाय ॥ णमो विणयपणयसुरिंदवंदवंदियकमारविंदाणं अरिहंताणं ।

अन्तः—

तस्स एसा दारिया दायव्वा ॥ छ ॥ **ग्रंथाग्रं** ११००० **एकादश सहस्राणि** ॥ छ ॥ मंगलं महाश्रीः ॥ संव १३८८ वर्षे माघ शुदि **१३** भौमे **स्तम्भतीर्थे वसुदेवहिंडी**

प्रथमखंडपुस्तकं लिखितम् ॥ छ ॥ शुभं भवतु ॥ छ ॥ कल्याणमस्तु समस्त-चतुर्विधसंघस्य ॥ छ ॥ यादृशं पुस्तके दृष्टं० ॥ १ शिवमस्तु सर्वजगतः० सर्वत्र सुखी भवतु संघः ॥ छ ॥ २

*

No. 211 : Vasudevahiṇḍī—Madhyamakhaṇḍa—Part I

वसुदेव हिंडी—मध्यम खंड—पूर्वार्ध

Folios – 219
Language – Paiśācī
Author – Dharmasenagaṇi Mahattara
Age of MS. – 1390 V.S.

Extent – Granthas 6600
Size – 30·5 × 2·2 inches
Condition – Fair

अन्तः—

वसुदेवहिंडि खंड । ग्रंथाग्रेण सहस्र षट् शतानि षट् ६६०० । उभयं ग्रंथ १७८०० ॥ छ ॥ संव १३९० वर्षे कार्तिक शुदि ७ शनौ दिने लिखितं ॥ छ ॥

*

No. 212 : Samarāiccakahā **समराइच्चकहा**

Folios – 317 स्ता ल्ह ग्रा
Language – Prakrit
Author – Ācārya Haribhadrasūri
Age of MS. – 1299 V.S.

Extent – Granthas 10000
Size – 33 × 2·5 inches
Condition – Good

आदिः—

॥ ॐ नमो वीतरागाय ॥

पणमह विजियसुदुज्जयणिज्जियसुरमणुयविसमसरपसरं ।
तिहुयणमंगलनिलयं वसहगइगयं जिणं **उसभं** ॥
परमसिरिवद्धमाणं पणट्ठमाणं विसुद्धवरनाणं ।
गयजोयं जोईसं सयंभुवं **वद्धमाणं** च ॥
सेसे वि य बावीसे जाइजरामरणबंधणविमुक्के ।
तेलोक्कमत्थयत्थे तित्थयरे भावओ नमह ॥
उवणेउ मंगलं वो जिणाण मुहलालिजालसंवलिया ।
तित्थपवत्तणसमए तियसविमुक्का कुसुमवुट्ठी ॥

देउ सुहं वो सुरसिद्धमणुयवंद्रेहिं सायरं नमिया ।
तित्थयरवयणपंकयविणिग्गया मणहरा वाणी ॥

अलं पवित्थरेण सुणह सोयव्वाइं । पसंसह पसंसणिज्जाइं । परिहरह परिहरियव्वाइं ।

अन्तः—

गुरुवयणपंकयाओ सोऊण कहाणयाणुराएण ।
अनिउणमयणा वि दढं बालाइअणुग्गहट्ठाए ॥

अविरहियनाणदंसणचरणगुणधरस्स विरइयं एयं ।
जिणदत्तायरियस्स उ अवयवभूएण चरियमिणं ॥

जं विरइऊण पुन्नं महाणुभावचरियं मए पत्तं ।
तेणं गुणाणुराओ होइ इहं सव्वलोयस्स ॥ छ ॥

गंथग्गमिमिमीए इमं छंदेणाऽणुट्ठुएण भणिऊण ।
पाएण दस सहस्सा हंदि सिलोयाण संठविया ॥ छ ॥ १०००० ॥ छ ॥

॥ ॐ ॥

वंशः श्री**पल्लिपालो**ऽस्ति सशाखः सत्यपर्ववान् ।
भूभृतोऽप्यधरीचक्रे येनैकच्छत्रितात्मना ॥ १ ॥

अजनि विनयपात्रं तत्र पुंरत्नचूडामणिरमलिनकीर्त्तिः **साढदेवा**ऽभिधानः ।
निरुपमजिनराजस्मेरपादारविंदाविचलविहितसेवाऽवाप्तविश्वप्रतिष्ठः ॥ २ ॥

शीलव्रतदृढा **साढू**संज्ञिता तस्य वल्लभा ।
जिनक्रमयुगांभोजे यन्मनो हंसकायते ॥ ३ ॥

भ्राताऽभूत् **साढदेवस्य देसलः** सत्यशालितः ।
पदमीनामधेयाऽथ प्रिया तस्य विवेकिनी ॥ ४ ॥

आसीत् श्रेष्ठिक**साढदेव**तनुभूर्**जाजाक**नामा जिन-
श्रेणिध्याननिशाणशाणितमतिप्राकाश्यनश्यत्तमाः ।
शश्वद्यस्य यशःप्रसूनमसमं राकानिशानायक-
ज्योतिःक्षालितनिर्मलांबरतलामोदाय यज्जातवान् ॥ ५ ॥

जाया तस्य **जयत्तुका** समभवद्दीनानुकंपारसा-
सारासिक्तविवेककंदलवनप्रस्तारबद्धादरा ।

नित्यध्यातजिनेश्वरांह्रिनखरुक्ध्वस्तांधकारांकुरे
यस्याश्चित्तगृहोदरे प्रतिपदं धर्मः सुखं खेलति ॥ ६ ॥

पुत्रो **लाखण**संज्ञितोऽजनि तयोः पुण्यैकपात्रं कृती
नीतिज्ञो विनयी नयी सुकुलजो दक्षः क्षमादक्षिणः ।
येनोत्तुंगनिजान्वयाह्वयमहाप्रासादमूर्ध्नि स्फुटं
दिग्विस्तारियशःसुकेननपटः प्रस्तारयामासिवान् ॥ ७ ॥

जाजाकस्याभवद् भ्राता **जसपाला**भिधः सुधीः ।
संतुकासंज्ञिका तस्य दयिता दानशालिनी ॥ ८ ॥

जातौ तयोः सुतौ **रत्न-धणसिंहा**भिधावुभौ ।
भगिनी **जाउका**नाम्नी बभूवाम्नायभूषणम् ॥ ९ ॥

अथ—

जायाऽजायत **लाखण**स्य कुलजा दानोद्यता **रुक्मिणी**
नाम्ना दीनसुवच्छलाऽवयविनी पुण्येंदिरा मंदिरे ।
यस्या मानसपंकजं त्यजति नो पक्षद्वयी निर्मलो
धर्मो हंसयुवा युतो वरलया तीर्थेशभक्त्याख्यया ॥ १० ॥

नरपतिरिति नामा **लाखण**स्यांगजन्मा तदनु **भुवनपाला**ख्यो **यशोदेव**संज्ञः ।
क्रमश इह तनूजा जज्ञिरे तस्य तीर्थाधिपतिसुगुरुपूजालब्धलक्ष्मीविकाशाः॥११॥

जाल्हणदेवीति सुता **जासी**नामा तथा परा पुत्री ।
सद्धर्मकर्मनिपुणा क्रमादिमा दुहितरोऽभूवन् ॥ १२ ॥

आसीत् कुलीनचरिता **नायिकदेवी**ति **नरपते**र्दयिता ।
अपरा च **गौरदेवी** तनुभूः **सामंतसिंहा**ख्यः ॥ १३ ॥

प्रिया **भुवनपाल**स्य **पउंदेवी**ति संज्ञिता ।
बभूव भाग्यभूः शीलरत्नरत्नाकरावनिः ॥ १४ ॥

यशोदेवस्य पत्नी **सोहरा**संज्ञा पतिव्रता जज्ञे ।
तस्याः समभूत् पुत्रः **सांगण**नामा स्फुरद्धामा ॥ १५ ॥

मातुस्तातो **राजपाला**ऽभिधानो मातुर्माता यस्य **राणी**तिनाम्नी ।
मातुर्भ्राता **राणिगो वूटडि**श्च मातुः पक्षो **लाखण**स्येत्थमुक्तः ॥ १६ ॥

श्रीमज्जिनेशप्रभुहस्तपद्माधिवासतो **लाखण**नामधेयः ।
तीर्थेशयात्रादिककर्मनिर्मलः कुलप्रदीपः सुजनोपकारी ॥ १७ ॥

अथान्यदा **लाखण** एष हृष्टः सुदृष्टशास्त्रार्थविनीतचेष्टः ।
भवस्वरूपं क्षणदृष्टनष्टं विभावयामास निशावसाने ॥ १८ ॥

प्रातः प्रयातः सुगुरोः समीपे तदेव तत्रैव तथा निशम्य ।
ततः प्रबोधार्कसुदृष्टवस्तुना समाधिना ध्यायति सर्वमप्यदः ॥ १९ ॥

तथाहि—

देहं दुःखैकगेहं जलनिधिलहरीचंचलं जीवितव्यं
संपत्तिः प्राणभाजां प्रसृमरपवनोद्भूतकेतूपमेया ।
सौंदर्यं सुभ्रुनेत्रांचलललितसमं बंधुसंगोऽप्यनित्यो
जैनं धर्मं विनाऽन्यन्नहि मनुजभवे शाश्वतं किंचिदस्ति ॥ २० ॥

दानशीलतपोभावभेदैर्धर्मश्चतुर्विधः ।
मुख्यतो यतयो दानमेवैकं संप्रचक्षते ॥ २१ ॥

यद्यपि त्रिविधं शास्त्रे तद् दानं ननु विश्रुतम् ।
तथापि ज्ञानदानान्नो दानमन्यत् प्रशस्यते ॥ २२ ॥

ज्ञानं श्रुताश्रितं प्रोक्तं श्रुतं शास्त्रमिति स्मृतम् ।
तच्च द्विधा समाख्यातं कल्पिताचरितक्रमात् ॥ २३ ॥

तद्द्वयोद्योतितं किंचिच्चरितं सुनिरूपये ।
इति चिंतयतस्तस्य स्मृतिगोचरतां गतम् ॥ २४ ॥

चरित्रं समरादित्यभूभुजः प्रशमास्पदम् ।
संसारिजीववैराग्यरसनिस्यंदभाजनम् ॥ २५ ॥

किंच—

द्वेषव्याघ्रहुताशनं शमधुनीपूरार्णवं दुर्णय-
ध्वांतध्वंसनभास्करं कलिमलप्रक्षालनैकामृतम् ।
एतत्सच्**चरितं** तु चारु **समरादित्येशितुः** शास्त्रतो
बद्धं श्री**हरिभद्रसूरि**गुरुणा संवेगसंगाय नः ॥ २६ ॥

यदिष्टं वस्तु संसारे तदिष्टेषु नियोज्यते ।
अन्यदिष्टं हि नो दृष्टं मातरं पितरं विना ॥ २७ ॥

इति मातृजयतुकाया निजपितृजाजाह्वयस्य पुण्याय ।
समरादित्यचरित्रं विलेखितं लाखणेनैतत् ॥ २८ ॥

येन द्रव्यमुपार्जितं शुभवशादेकांगवीरेण तत्
क्षेत्रे सप्तमिते निवेश्य विहिता सद्वृत्तिरूपा वृतिः ।
तत्सीम्नि प्रकटो जिनेशसुगुरोरादेशतः शाश्वतो
जैनः **श्रीसमरार्क**पुस्तकतया घाटः समारोपितः ॥ २९ ॥

नंदनवभानुवर्षे १२९९ पित्रोः सुकृताय **लाखणः** कुलजः ।
समरादित्यचरित्रव्याख्यानं कारयामास ॥ ३० ॥

यावन्नालति नागराट् नलिनति क्षोणीतलं दिक्ततिः
पत्रस्तोमति केसरत्यहिमरुक् किं चांबरं भृंगति ।
तावत्तत्**समरार्कभूपचरितं** चैतन्यविस्तारकं
श्रोतॄणां शमसंपदं वितनुतां व्याख्यायमानं बुधैः ॥ ३१ ॥

नंदनवभानुवर्षे १२९९ **श्रीरत्नप्रभसूरि**णा शुभध्यानात् ।
श्रीस्तंभतीर्थनगरे व्याख्यातं कार्त्तिके मासि ॥ ३२ ॥

शिवमस्तु सर्वजगतः परहितनिरता भवंतु भूतगणाः ।
दोषाः प्रयांतु नाशं सर्वत्र सुखी भवतु संघः ॥ ३३ ॥ छ ॥

*

No. 213 : Bhuvansundarīkathā

भुवनसुंदरीकथा

Folios – 271 Extent – Granthas 11300
Language – Prakrit Size – 28.5 × 2.2 inches
Author – Vijayasiṃhasūri Condition – Good
Age of MS. – c. First half of 13th cent. V. S.
General Remarks – Folio 1 contains a very nice picture-decoration. Last 2 or 3 folios appear to have been affected by five on one edge. The original *Puṣpikā-Praśasti* probably containing the age of the ms. etc. has been erased and a fresh *Praśasti* in the name of Ratnādevī is introduced in its place.

॥ ॐ नमः सर्वज्ञाय ॥

आदिः—

पढमं चिय पढमजिणस्स नमह नहमणिमऊहरमणीयं ।
अंकुरियमोक्खपायवबीयनिहाणं व पयकमलं ॥

सो जयइ **वद्धमाणो** घणो व्व इह जस्स वयणवारिभरो ।
नियभासाय रसेण व तरूण जीवाण परिणमइ ॥

अइनिम्मलाए नमिमो अवसेसजिणावलीए पयकमले ।
जीए सुत्तावलीए व एक्को चिय सुत्तसारत्थो ॥

पणमह पणमंतमहाकइंदसंकंतनयणपडिबिंबं ।
कयनीलुप्पलपूयं व **भारई**चरणनहनिवहं ॥

जाओ जाण पसाएण मज्झ मूयस्स वयणविन्नासो ।
ताण अणंतगुणाणं गुरूण पणमामि पयकमलं ॥

ते कइणो हियमहोयहिम्मि सुमहत्थरयणरमणीया ।
उल्लसइ जाण वाणी उयरुयरितरंगमाल व्व ॥

सुकइत्तणावलेवं वहंति कह ते न जाण उभयं पि ।
वयणंमि वसा वाणी न मणम्मि सयत्थनिप्फत्ती ॥

पयपूरणमेत्तेणं अदिट्ठपरमत्थवत्थुनाणेणं ।
कव्वेण कुवुरिसेण व कइकुलमज्झे परं हासो ॥

पढमकइचक्कवट्टीण नमह सिरिइंदभूइपमुहाण ।
सुयसायरम्मि जाणं इयरकई तणमिव तरंति ॥

सिरिपालित्तय-कइबप्पहट्टि-हरिभद्दसूरिपमुहाण ।
किं भणिमो जाणऽज्ज वि न गुणेहिं समो जए सुकई ॥

वासे विरयम्मि जए कालंतरिए य **कालिदासम्मि** ।
धणवालो सुकइत्तणभारुव्वहणम्मि जइ धवलो ॥

सच्छंदपयपयारो निरभिप्पायप्पहासणपरो य ।
सुकइत्तणगहगहिओ बुहाण हासं गमिस्सामि ॥

ते कत्थ महाकइणो रविणो व्व जए पयासियपयत्था ।
कत्तो खज्जोया इव मारिसकइणो पयइतुच्छा ॥
जइ वेवं तह वि ससत्तिसरिससत्तोवयारहियएण ।
अहमुज्जुत्तो न उणो सुकइत्तगुणाहिमाणेण ॥

अन्तः—

एत्थ समप्पइ सिरि**भुयणसुंदरीनामवरकहा** एसा ।
फुडवियडसललियक्खरगाहाहिं विणिम्मिया रम्मा ॥
इह आसि जयपसिद्धो निम्मल**नाइल्लकुल**समुब्भूओ ।
तवसीलसंजमरओ **समुद्दसूरि** त्ति आयरिओ ॥
नियहत्थदिक्खिएणं सीसेणं तस्स अणुवमगुणस्स ।
सिरि**विजयसीह**नामेण सूरिणा विरइया एसा ॥ छ ॥
लक्खणछंदविहीणं भट्टालंकारमागमविरुद्धं ।
जं किं पि एत्थ रइयं सोहंतु विसारया तमिह ॥
इह आसि **मोढवंसे डाउय**सेट्ठि त्ति सावओ गुणवं ।
तस्सासि **नेढ**नामा पियभज्जा सीलगुणकलिया ॥
पुन्नोदओ व्व ताणं पसंसणीओ सुओ समुप्पन्नो ।
गोवाइच्चो नामं सव्वगुणालंकियसरीरो ॥
जस्स पसंतं रूवं वेसो वि अणुब्भडो महुरवाणी ।
परउवयारे बुद्धी सुपत्तदाणे महावसणं ॥
भत्ती जिणिंदचरणे अविचलसम्मत्तभावियं चित्तं ।
विसएसु अलोलुत्तं विणिग्गहो रायदोसेसु ॥
इयमाइविविहगुणगणसंखं को मुणइ तस्स धन्नस्स ।
खीरोबहिंम्मि उज्जलकल्लोलाणं व परिमाणं ॥
अह तस्स आसि पुव्विं माउपिया **पासिलो** त्ति सुपसिद्धो ।
सोमेसरनयरवत्थव्वो ॥
तस्स नियकम्मपरिणइवसेण साहीणनियकलत्तस्स ।
कह वि न जाओ पुत्तो संताणं जो समुद्धरइ ॥

तो तेण अपुत्तेणं दोहित्तियजायपक्खवाएण ।
पुत्तत्तणेण गहिओ **गोवाइच्चो** बहुगुणड्ढो ॥
मायामहेण तेणं **सोमेसर**संठियं सुहाधवलं ।
गोवाइच्चस्स तओ दिन्नं धवलहरमुत्तुंगं ॥
गोवाइच्चेण वि मुणियविरससंसारखणिगभावेण ।
सिरिउज्जयंततित्थे समप्पियं **नेमिनाह**स्स ॥
भणिओ य तेण संघो **गोवाइच्चेण** पंजलिउडेण ।
मुणिसंघनिवासत्थं एस मढो अप्पिओ तुम्ह ॥
अह तम्मि सुहाधवले तिभूमिए परमरम्मयानिलए ।
गोवाइच्चविदिन्ने संघमढे विरइया एसा ॥
तस्स उवट्ठंभेणं वत्थासणसयणपत्तमाईहिं ।
निच्चिंतमाणसेणं रइया सिरि**विजयसीहेण** ॥
निप्फाइया य एसा लिहाविया तेण पोत्थयसएसु ।
गुणपक्खवायमणसा पयासिया सयलभुयणम्मि ॥ छ ॥
अणवच्छन्नो पसरइ जा जिणधम्मो विदेहभूमीसु ।
ता **भुवणसुंदरिकहा** वित्थरउ जयम्मि अक्खलिया ॥ छ ॥

[लेखकप्रशस्तिः]

श्रीमद्**गूर्जरवंश**प्रभवः संभवदनेकगुणविभवः ।
साधुहरिचंद्रसूनुः **पुण्यश्री**कुक्षिसंभूतः ॥ १ ॥
दुस्थार्थिसंतापहरः प्रसिद्धः स्वच्छाशयश्चारुगुणांचितश्च ।
मुक्तोपमानो वसुमान् सुवृत्तः समस्ति साधु**र्नयपाल**नामा ॥ २ ॥ युग्मम् ।
तस्यास्ति जाया **रयणा**भिधाना दानादिसद्धर्मरता प्रधाना ।
पुत्रास्त्वमी प्रौढविवेकचर्याख्यातास्त्रयो निर्मितसंघकार्याः ॥ ३ ॥
आद्यो वदान्यः कृतिलोकमान्यः प्राज्ञः सुधन्योऽजनि **कीर्तिसिंहः** ।
दानोद्यतोऽन्यस्त्विह **देवसिंहः साल्हा**भिधः साधुवरस्तृतीयः ॥ ४ ॥
साधुनयपालपत्नी **रयणादेवी** विवेकधर्मज्ञा ।
पुस्तकमेनं श्री**भुवनसुंदरी**सत्कथासत्कम् ॥ ५ ॥

आत्मश्रेयोर्थमथ व्याख्यापयितुं जनोपकाराय ।
जगृहे मूल्येन मुदा बाणरसशिखींदुमितवर्षे १३६५ ॥ ६ ॥
पुष्पदंताविमौ यावद्वर्त्तेते गगनांगणे ।
बुधैर्व्याख्यायमानोऽयं तावन्नंदतु पुस्तकः ॥ ७ ॥
भुवनसुंदरीकथापुस्तकं सा० **नयपालभार्या रयणादेव्याः** सत्कं । **ग्रंथाग्रं**
११०००३०० समाप्तः ॥

*

No. 214 : **Pruthvīcandracaritra**

पृथ्वीचंद्रचरित्र

Folios – 183
Language – Prakrit
Author – Śāntisūrī
Age of MS. – 1212 V.S.

Extent – Granthas 7500
Size – 28.7 × 2.5 inches
Condition – Fair
Date of Composition – 1631 Vīra Saṁ. = 1161 V. S.

General Remarks – Only a half of folio 178 is preserved. All the folios have been bitten by mice in the middle and on one side, and several folios at the end appear to be just about to break into pieces from the middle. All the same the ms. is still in good condition.

आदिः—

.... सर्वज्ञाय ॥
वंदे कुवलयभूसणमणुन्नसाओदयं विसालच्छं ।
विब्भमरहियं माणससरं व पढमं जिणं पढमं ।
....
अलमेत्थ वित्थरेणं भो भो सुयणा सुणेह धम्मंगं ।
चरियं सुचरियरम्मं महरिसिणो **पुहइचंदस्स** ॥

अन्तः—

आसी **कुंदेंदुसुद्धे** विउलससिकुले चारुचारित्तपत्तं
सूरी सेयंबराणं वरतिलयसमो **सव्वदेवाभिहाणो** ।
नाणासूरिप्पसाहापहियसुमहिमो कप्परुक्खो व्व गच्छो
जाओ जत्तो पवित्तो गुणसुरसफलो सुप्पसिद्धो जयंमि ॥

तेसिं चाऽऽसी सुयजलनिही खंतदंतो पसंतो
सीसो वीसो सियगुणगणो **नेमिचंदो** मुणिंदो ।
जो विक्खाओ पुहइवलए उग्गचारी विहारी
मन्ने तो से मिहिरससिणो तेयकंतीहि तुल्ला ॥
तेसिं च सीसो पयईजडप्पा अदिट्ठपुव्विल्लविसिट्ठसत्थो ।
परोवयारेक्करसावियज्झो जाओ निसग्गेण कइत्तकोड्डी ॥
जो **सव्वदेव**मुणिपुंगवदिक्खिएहिं साहित्ततक्कसमएसु सुसिक्खिएहिं ।
संपाविओ वरपयं सिरि**चंदसूरि**पुज्जेहि पक्खमुवगम्म गुणेसु भूरि ॥
संवेगंबुनिवाणं एयं सिरि**संतिसूरि**णा तेण ।
वज्जरियं वरचरियं **मुणिचंद**विणेयवयणाओ ॥
जइ किंचि अजुत्तं वुत्तमेत्थ मइजड्डुरहसवित्तीहिं ।
तमणुग्गहबुद्धीए सोहेयव्वं छइल्लेहिं ॥
इगतीसाहियसोलससएहिं १६३१ वासाण निव्वुए वीरे ।
कत्तियचरिमतिहीए कित्तियरिक्खे परिसमत्तं ॥
जयइ पयइसुद्धं अंगुलीवत्तवत्तं सहयसुहयगंधं भव्वभिंगोहजुट्ठं ।
वियसियममिलाणं पावपंकक्कमुक्कं कयजयसरसोहं वीरपायारविंदं ॥ छ ॥
इय **पुहइचंदचरिए** एक्कारसमं भवगहणं समत्तं ॥ छ ॥
गंथसिलोगपमाणं सत्त सहस्साइं पंच य सयाइं ।
इय **पुहइचंदचरिए** विणिच्छियं पायसो गणियं ॥
अंकतोऽपि ७५०० ॥ समाप्तं **पृथ्वीचंद्रचरितमिति** ॥ छ ॥
भव्यांभोरुहभानुभिर्भवमहीभृच्छेददंभोलिभि-
र्मोहानोकहमातरिश्वभिरलं शीलामृतांभोधिभिः ।
विश्वे विश्वकवीन्द्रचक्रतिलकैर्नो केवलं नाम्ना(नामभिः)
बिभ्राणैर्मनसा च— —(शान्ति)मतुलां चारित्रिणां नायकैः ॥ छ ॥
पूज्यैर्निर्जैर्दलितदर्पककार्मुकज्यैर्योऽचीकरत् कृतनतिश्चरणारविंदे ।
पृथ्वीविधोश्चरितमुत्तममेतदादौ तेनैव चारु**मुनिचन्द्र**मसा—(व्य)लेखि । छ ॥

[लेखकप्रशास्तिः]

वन्नड्ढो वरपत्तपत्तसाहिओ साहाभिरामो सया
सच्छाओ गुरुपव्वसंतइजुओ आबद्धमूलो भुवि ।
उत्तुंगो फलसाउणेगकलिओ पक्खी—(ण) संवासओ
विक्खाओ **सिरिभिल्लमाल**तणओ वंसोऽत्थि वंसोवमो ॥ १ ॥
वंसे तम्मि पवित्तवित्तकलिओ मुत्ताहलं वाऽमलो
उप्पन्नो वरसेयकित्तिनिलओ लोयाण संतोसओ ।
दाणाणंदियसाहुसावयजणो दीणेसु कंपापरो
सिद्धू णेगमवल्लहो य पवरो सिट्ठी पसिद्धो जणे ॥ २ ॥
गुज्जरवि–[ल]याहरणे धणकणयसमिद्धिसंपयाकलिए ।
गामे **समी**भिहाणे जेणाऽऽजम्मम्मि संवसियं ॥ ३ ॥
तस्साऽऽसी वररूवभूसियतणू सीएव सीलव्वया
लज्जादाणदयाविवेयभवणं संमत्ततत्ते रया ।
निच्चं देवगुरूण पूयणपरा भत्ता सया भत्तुणो
भज्जा **संपइ**सन्निया य सुहया लच्छि व्व –(सा)रंगिणो ॥ ४ ॥
दक्खो सूरो चाई विणयजुओ नाणरूवसंपन्नो ।
खलिगनामा सिट्ठी अंगरुहो तेसि संजाओ ॥ ५ ॥
भज्जा तेण सुधम्मधम्मकलिया लायन्नपुन्नोदही
दक्खिन्नस्स गिहं दयाय भवणं दीणेसु कंपालुया ।
सीलालंकियविग्गहा सुचरिया चित्तेण तुंगासया
उव्वूढा इह छद्दु –(इ)त्ति पवरा खाइं गया सज्जणे ॥ ६ ॥
तीए जाया पुत्ता सज्झायज्झाणदाणकयचित्ता ।
देवगुरुपूयणरया साहम्मियवच्छला सुहया ॥ ७ ॥
पढमो ताण पसिद्धो **पासड**नामो य **नाहडो** बीओ ।
तइओ **सिद्धू** सच्छो तुरिओ उण **आमिगो** दक्खो ॥ ८ ॥
पंचमओ तह **सोढू** विक्खाओ सज्जणाण मज्झंमि ।
भयणीउ दोन्नि तेसिं संजाया बंधुयणपुज्जा ॥ ९ ॥

चानणनामा पढमा बीया तह **पाहुय** त्ति विक्खाया ।
सीलालंकियदेहा जिणधम्मरया सयाकालं ॥ १० ॥

भत्तारभत्ता जिणधम्मजुत्ता जाऊभिहाणा अह **नाहडस्स** ।
जाया सुजाया वरसीलवंता **सिद्‌धूयभज्जा** तह **वालुयक्खा** ॥ ११ ॥

जा–(या) –(पु)णो **मोहिणि**नामधेया भज्जा विणीया इह **आमिगस्स** ।
लच्छीहरस्सेव जहेव लच्छी **सोढूयभज्जा लखमी** पसिद्धा ॥ १२ ॥

विन्नाणनाणकुसला वियक्खणा **नाहडस्स** दो तणया ।
पाजय-चाहडनामा संपन्ना रूवगुणकलिया ॥ १३ ॥

चंदो इव जुन्हाए धवलिंतो नियमंदिरं सहसा ।
चंदप्पहु त्ति तणओ संजाओ **सोढ**देवस्स ॥ १४ ॥

अन्नया **सोढुए**णेवं चिंतियं हियए सुहं ।
कायव्वो विउसा धम्मो सो य नाणाउ जायए ॥ १५ ॥

........वत्थुसाहणपरं नाणं सुहाणं निही
नाणं सिद्धिपुरंधिसंगमकरं नाणं विवेयावहं ।

नाणं दाणपहाणमग्गिमगुणं नाणं नयासावहं
नाणं कम्मविओगकारणमहो ! नाणं च दीवोवमं ॥ १६ ॥

नाणं विणा नो परमत्थि अन्नं मुक्खस्स संसाहगमेव वत्थू ।
लेहावणे तस्स समुज्जमो ता जुत्तो सया भव्वजणाण लोए ॥ १७ ॥

इइ सोऊणं(? सोइऊण) एयं **पुहईचंदस्स राइणो चरियं** ।
बहुविहकहानिबद्धं लिहावियं **सोढदेवेण** ॥ १८ ॥

कीलो सेसोत्तिमंगं तदुवरि धरणीचक्कमं तस्स मेरू
थासो डंडोवमो सो हिमगिरिवलयं कप्परं खीरसिंधू ।

एवं विस्सं कुलालोवगरणतुलणा धारए जाव रम्मं
तावेयं पोत्थयं भो ! जणियजणमणाणंदणं नंदउ त्ति ॥ १९ ॥ छ ॥

संवत् १२१२ वर्षे ज्येष्ठ शुदि १५ गुरावद्येह **श्रीमदणसिंह(हिल)नयर**समावासे समधिगतपंचमहाशब्दवाद्यमानं **चौलुक्य**कुलकमलकलिकाविकासं **कर्न्नाटराय**मानमर्द्दनकरं

सपादलक्षराष्ट्रवनदहनदावानलं **मालवे** राष्ट्रे निजाज्ञायाः संस्थापनकरं **मूलराजपट्टोद्वहन**-धुराधौरेयं पार्वतीप्रियवरलब्धप्रसादं इत्यादिसमस्तराजावलीमालालंकारविराजमानश्री**कुमर-पालदेव**विजयराज्ये तत्पादावाप्तप्रसादमहाप्रचंड दंडनायकश्री**वोसरिलाटदेशमंडले मही-दमुनयो**रंतराले समस्तव्यापारानु(न्) परिपंथयंतीत्येतस्मिन् काले **अणेरग्रामे** नियमसंजम-स्वाध्यायध्यानानुरतपरमभट्टारकआचार्यश्री**मदजितसिंहसूरि**कृते श्रावक**सोढूकेन** परमश्रद्धा-युक्तेन **पृथ्वीचंद्रचरित्रपुस्तकं** विशुद्धबुद्धिना लिखापितम्। लिखितं च पंडित **मदनसिंहे**-नेति ॥ .... ॥ मंगलं महाश्रीः ॥ छ ॥

*

No. 215 : Pṛthvīcandracaritra—Prakrit Gadya-Padya

पृथ्वीचन्द्रचरित्र—प्राकृत गद्य-पद्य

Folios – 151
Size – 27·7 × 2.2 inches.
Language – Prakrit
Condition – Injured
Author – Śāntisūri
Date of Composition – 1631 Vīra Saṃvat = 1161 V. S.
Age of MS. – c. Beginning of 13th cent. V.S. or end of 12th cent. V.S.
General Remarks – Correct but incomplete. Annotations of difficult words given in the margin. Very nice picture-decorations are found at the end of every chapter. The starting folios are highly damaged.

*

No. 216 : Ratnacūḍakathā Pūjāvidhāna

रत्नचूडकथा पूजाविधान

Folios – 109
Extent – Gāthās 3081
Language – Prakrit
Size – 26.7 × 2.2 inches
Author – Devendragaṇi (Nemicandrasūri)
Condition – Good
Age of MS. – 1221 V. S.

आदिः—

॥ नमो जिनाय ॥

नमह नयनमिरनरवइसरिसरुहवियासणं भुवणपणयं।
निहयतमतिमिरनियरं वीरजिणदिणेसरं सिरसा ॥
जयइ मुहकंतिनिज्जियसारयरयणीयरा य सुयदेवी।
दुत्तरसुयरयणायरतरणतरंडोवमपसाया ॥ २ ॥

इय नमिउं **वीर**जिणं थोऊण **सरस्सइं** च भावेणं ।
भवियजणबोहणत्थं उवएसं किंचि वोच्छामि ॥ ३ ॥

जम्मजरमरणसलिलं संसारमहोयही भमंतेहिं ।
दारुणदुहवडवानलभसुलियगत्तेहि सत्तेहिं ॥

सासयसुहसोक्खपहे कायव्वो उज्जमो पयत्तेण ।
लद्धूण मणुयजम्मं समत्थपुरिसत्थसिद्धियरं ॥

मोक्खपहो जिणधम्मो चिंतामणिकप्पपायवसमाणो ।
चउहा भणिओ सो दाणसीलतवभावणामइओ ॥

धम्मस्स य संसिद्धी जिणिंदपूयाए जायए तह य ।
कल्लाणकारणाओ पंचनमोक्कारजोगाओ ॥

तेसि फलजाणणत्थं चरियाइं सुणेह भव्वसत्ताणं ।
न हु अमुणियफलभावा विउसा कत्थ वि पयट्टंति ॥

अओ—

जह **रयणचूड**राया पंचहिं दारेहि परिगओ मईमं ।
जिणपूयाइविहाणा कल्लाणपरंपरं पत्तो ॥

अन्तः—

सोऊण चरियमेयं तु **रयणचूडा**इयाण सत्ताणं ।
जिणपूयाइसु जत्तो कायव्वो भव्वसत्तेहिं ॥

मिच्छत्तमोहमहणं भवसायरतरणपवहणं परमं ।
कुसमयविणासणं सिरिजिणिंदवरसासणं जयउ ॥

सयलजयजंतुपत्थियसुहफलया कप्पपायवलय व्व ।
सग्गापवग्गसंगमनिबंधणं जयइ जिणपूया ॥

सयलसुहसिद्धिकरणो दुहहरणो पयडपावविसहरणो ।
जिणसासणस्स सारो जयइ सया पंचनवकारो ॥

धणओ धणकामीणं कामत्थीणं च सव्वकामकरो ।
दाणाइओ वि धम्मो जिणिंदभणिओ जए जयइ ॥

भद्दं सरस्सईए देवीए समणुभावओ जीसे ।
मंदमई विउसाणं सदा सुविउसायए पुरिसो ॥

आसि सिरिदेवसूरी दुव्वहसीलंगगुणगणाधरणो ।
उज्जयविहारनिरओ तग्गच्छे तयणु संजाओ ॥

सिरिनेमिचंदसूरी कोमुइचंदो व्व जणमणाणंदो ।
तयणु महिवलयपसरियनिम्मलकित्ती विमलचित्तो ॥ ७ ॥

समणगुणदुव्वहधुराधारणधोरेयभावमणुपत्तो ।
सिरिउज्जोयणसूरी सोमतणू सोमदिट्ठी य ॥ ८ ॥

धम्मो व्व मुत्तिमंतो पयपंकयरेणुनासियतमोहो ।
जसदेवसूरिनामो रवि व्व तवतेयसा जुत्तो ॥ ९ ॥

दूरविणिज्जियमयणो रूवेण मणेण सयलगुणनिलओ ।
आणंदियसयलजणो पवरो पज्जुन्नसूरिवरो ॥ १० ॥

निबिडमइमुणियदुग्गमकव्वो जीवो व्व नायसत्थत्थो ।
मुसुमूरियमयमयणो सूरिवरो माणदेवो त्ति ॥

उद्दामकित्तिसद्दो मणहरदेवो महामई कुसलो ।
दंसणमेत्ताणंदियजिणवयणपउट्ठलोगो वि ॥

पयडियवरसत्थत्थो वयणट्ठियसरसइ व्व पडुवयणो ।
सिरिदेवसूरिनामो समत्थलोगम्मि विक्खाओ ॥

तह चेव तम्मि गच्छे उज्जोयणसूरिणो पवरसीसो ।
जाओ गुणरयणनिही उज्झाओ अंबदेवो त्ति ॥

कोमुइमयंकमंडलसोमसरीरस्स संतचित्तस्स ।
वरमइणो धम्मसहोदरेण मुणिचंदसूरिस्स ॥

*गणिणा देविंदेणं सीसावयवेण तस्स तणुमइणा ।
एसा कहिया कहिया अक्खरबंधेण संखित्ता ॥

---

*" सुयदेविपसाएणं सीसावयवेण तस्स तणुमइणा ।
एसा कहिया रइया उ सूरिणा नेमिचंदेण " ॥ प्रत्यन्तरे ॥

आणंदियविउसासुं अन्नासु कहासु विज्जमाणासु ।
एसा हासट्ठाणं जाणंतेणावि विउसाणं ॥

कलहंसगइविलासेण संचरंतो हु धट्ठबलिपुट्ठो ।
हासट्ठाणं जायइ जणम्मि निस्संसयं जेण ॥

किंतु इह सुयणरयणा हासोचियमवि हसंति न कया वि ।
अवि य कुणंति महग्घं गुणाणमारोवणेणेत्थ ॥

इइ बलियक्कारेणं कव्वविहाणम्मि जायवसणेणं ।
[1]एसा कहिया रइया तेणऽप्पाणाणुसरणत्थं ॥ छ ॥

तोऽणुग्गहं कुणंता सुणंतु गिण्हंतु निग्गुणं पि इमं ।
सोहंतु दोसजालं दक्खिन्नमहोयही सुयणा ॥

[2]**डिंडिलवद्दनि**वेसे पारद्धा संठिएण सम्मत्ता ।
चड्डावल्लिपुरीए एसा फग्गुणचउम्मासे ॥

पज्जुन्नसूरिणो धम्मनत्तुएणं च सुयणुसारेणं ।
गणिणा **जसदेवेणं** उद्धरिया एत्थ पढमपई ॥ छ ॥

पूजादिविधानफलं समाप्तम् ॥ छ ॥ छ ॥ **रत्नचूडकथा** ग्रं० ३०८० ॥ छ ॥ संवत् १२२१ ज्येष्ठ सुदि ९ शुक्रदिने अद्येहश्रीम**दणहिलपाटके** महाराजाधिराजजिन-शासनप्रभावक परमश्रावकश्री**कुमरपालदेव**राज्ये । श्री**चड्डापल्ल्यां** श्री**कुमरपालदेवप्रसादा-स्पदश्रीधारावर्ष**नरेन्द्रराज्ये श्री**चक्रेश्वरसूरि**-श्री**परमानंदसूरि**प्रभूपदेशेन श्री**चड्डापल्लिपुरी**-वास्तव्य श्रे० **पूना**श्रावकेण **आशाचंद्र-आशाधर-पोइणि-छाहिणि-राजू**प्रमुखमानुषसमे-तेन इदं **ज्ञाताधर्मकथांगरत्नचूडकथापुस्तकं** लेखितमिति ॥ छ ॥

शिवमस्तु सर्वजगतः परहितनिरता भवंतु भूतगणाः ।
दोषाः प्रयांतु नाशं सर्वत्र सुखी भवतु लोकः ॥ १ ॥

श्रीचक्रेश्वरसूरि-श्रीपरमानंदसूरि-श्रीयशःप्रभसूरीणाम् ॥

*

---

१ कव्वब्भासो विहिओ तेणऽप्पा° प्रत्यन्तरे ॥ २ गाथेयं प्रत्यन्तरादवतारिताऽत्र ॥

No. 217 : Ratnacūḍakathā—Pūjāvidhāna

रत्नचूडकथा—पूजाविधान

Folios – 255
Language – Prakrit
Author – Devendragaṇi (Nemicandrasūri)
Age of MS. – 1289 V.S.
Extent – Granthas 4800
Size – 14·5 × 2·2 inches
Condition – Good

*

No. 218 : Ratnacūḍakathā—Pūjāvidhāna

रत्नचूडकथा—पूजाविधान

Folios – 171
Language – Prakrit
Author – Devendragaṇi (Nemicandrasūri)
Size – 14.7 × 2.2 inches
Condition – Good
Age of MS. – c. Ending of 13th cent. V. S.

General Remarks – Folios Nos. 209-212, 221 are missing.

*

No. 219 : Ratnacūḍakathā—Pūjāvidhāna

रत्नचूडकथा—पूजाविधान

Folios – 72 to 157
Language – Prakrit
Author – Devendragaṇi (Nemicandrasūri)
Size – 18.2 × 1.7 inches
Condition – Good
Age of MS. – c. Latter half of 13th cent. V. S.

General Remarks – Incomplete.

*

No. 220 : Pāṇḍavacaritamahākāvya Padya—with Bījaka

पांडवचरितमहाकाव्य पद्य-बीजकसह

Folios – 263
Language – Sanskrit
Author – Maladhārī Devaprabhasūri
Size – 32.5 × 2.5 inches
Condition – Good
Age of MS. – c. First half of 14th cent. V. S.

General Remarks – Folio 1 contains three illustrations *viz.*, those of Bhagavān Ṛṣabhadeva, Neminātha and Pārśvanātha. Folio 2 has the pictures of Śrīlakṣmī, Ambikā and Padmāvatī—the three Śāsanadevīs of the above three Tīrthaṅkaras. Folio 263 contains three illustrations: (1) of Bhagavān Neminātha, (2) Yudhiṣṭhira and Draupadī, (3) Bhīma-Arjuna-Sahadeva-Nakula.

॥ ॐ नमः सर्वज्ञाय ॥

आदिः—

श्रियं विश्वत्रयत्राणनिष्णः पुष्णातु वः प्रभुः ।
शंकरः पुंडरीकाक्षः श्रीमन्नाभिसमुद्भवः ॥ १ ॥

पुण्यप्रसूतिः श्रीनेमेः पातु वो देशनागवी ।
घासः स्मरादयो यस्याः क्षीरं मोक्षसुखं पुनः ॥ ૨ ॥

पार्श्वनाथः स वः पायाद्यदंगद्युतिसागरे ।
प्रवालकंदलायन्ते फणिरत्नप्रभांकुराः ॥ ३ ॥

जयन्ति वर्द्धमानस्य जितदंभोलिवैभवाः ।
मोहांधतमसध्वंसहेलयः सत्त्वकेलयः ॥ ४ ॥

चरित्रं पांडुपुत्राणां पवित्रमभिदध्महे ।
श्रुतं हितोपदेशाय यज्जने पर्यवस्यति ॥ ५ ॥

अन्तः—

इति **मालधारिश्रीदेवप्रभसूरि**विरचिते **पाण्डवचरिते** महाकाव्ये बलदेवस्वर्गगमन-श्रीनेमिनाथ-पाण्डवनिर्वाणवर्णनो नाम अष्टादशः सर्गः ॥ छ ॥

श्रीकोटिकाख्यगणभूमिरुहस्य शाखा
या मध्यमेति विदिता विटपोपमेऽस्याः ।
श्रीप्रश्नवाहनकुले सुमनोऽभिरामः
ख्यातोऽस्ति गुच्छ इव **हर्षपुरीय**गच्छः ॥ १ ॥

तत्राऽजनि श्रुतसुधाम्बुधिरिन्दुरोचिः-
स्पर्द्धिष्णुकीर्त्तिविभवोऽ**भयदेवसूरि**ः ।
शान्तात्मनोऽप्यहह निस्पृहचेतसोऽपि
यस्य क्रियाऽखिलजगज्जयिनी बभूव ॥ २ ॥

बद्धक्रीड इवावतीर्यपरमज्योतिर्विवर्त्तः क्षितौ
तत्पट्टे वरचन्द्रमाः समजनि **श्रीहेमसूरिप्रभुः** ।
चित्रं यद्वचनामृतानि नृपतिः **श्रीसिद्धराजः** पपौ
विश्वेषामपि लेभिरे तनुभृतामायूंषि वृद्धिं पुनः ॥ ३ ॥

तस्य पदे मदनादिद्वेषिजयी **विजयसिंह**सूरिरभूत् ।
यद्वपुषि स्पर्द्धाऽभूल्लावण्यामृतशमामृतयोः ॥ ४ ॥

श्रीचन्द्रसूरिरभवत्तदीयपदभूषणं गुणैकनिधिः ।
विद्यायाश्च मदस्य च येन वितेने चिरवियोगः ॥ ५ ॥

धर्मज्ञानविवेकसंयमतपः संकेतकेलीगृहं
स श्रीमान् **मुनिचन्द्र**सूरिरभवत्तत्पट्टभूषामणिः ।
ब्रूमस्तत्करपुष्करस्य महिमा किं नाम यत्सौरभै-
र्गण्यन्ते बत मादृशा अपि जनैः संख्यासु संख्यावताम् ॥ ६ ॥

श्री**देवप्रभ**सूरिर्बभूव तच्चरणकमलरोलम्बः ।
येन कलेः कीर्त्तिरवैरभितो मुखरीकृतं भुवनम् ॥ ७ ॥

मुनिचन्द्रसूरिपट्टे श्री **देवानन्द**सूरयोऽभूवन् ।
स्तोत्राय यद्गुणानां ध्रुवं न वेधा अपि सुमेधाः ॥ ८ ॥

तेषां कल्पतरुत्रिविष्टपगवीचिंताश्मवैहासिका-
दादेशात् कविमार्गवल्गनकलानैपुण्यशून्यैरपि ।
श्री**देवप्रभसू**रिभिस्तनुभुवां पाण्डोश्चरित्रं किम-
प्येतत्तद्विबुधादिशिष्यहृदयोल्लासार्थमग्रथ्यत ॥ ९ ॥

श्री**यशोभद्र**सूरीणां तथाऽत्र व्यापृता दृशः ।
यथैतदगमत् सर्वविद्वलोकावलोक्यताम् ॥ १० ॥

ज्ञानैकमयमूर्त्तीनामस्मिन्नवरसान्विते ।
श्री**नरचन्द्र**सूरीणां प्रज्ञया कतकायितम् ॥ ११ ॥

प्रीत्याऽवलोकनेनैव कर्णक्रोडनवातिथेः ।
कर्त्तुमातिथ्यमर्हन्ति ग्रन्थस्यास्य मनीषिणः ॥ १२ ॥

मङ्गलं महाश्रीः ॥ छ ॥

अम्बिकासेवितः शश्वद् भवद्वेषी गुणाकरः ।
श्रीमा**न्नेमिकुमारो**ऽयं नूतनोऽस्तु सदा श्रिये ॥ १ ॥

अस्त्यस्ताघः **पूर्णराज**प्रसादाद् वृद्धिं प्राप्तः सुस्थितश्रीर्न दीनः ।
श्री**श्रीमालो** नाम वंशो विशालश्चित्रं जाड्यानाश्रयो पारिजातः ॥ २ ॥

तद्वंशे **महगी**नामभार्यः कार्यविशारदः ।
यशोराजो यशोराजीराजी राजीवलोचनः ॥ ३ ॥...........

No. 221 : Pāṇḍavacaritamahākāvya—Part II Sarga 11–18

पांडवचरित महाकाव्य—द्वितीय खंड—सर्ग ११–१८

Folios – 279
Language – Sanskrit
Author – Maladhārī Devaprabhasūri

Size – 14·5 × 2·2 inches
Condition – Good
Age of MS. – c. First half of 14th cent. V.S.

अन्तः—

कल्याणैकनिकेतनं सुमनसां वासो गुरुष्वग्रणी-
गोत्रेषु प्रवरः पुनाति जगतीं **श्रीमालभूरन्वयः** ।
चित्रं यत्र न मित्रमंडलमिदं नो वा कलावानपि
स्थानाप्राप्तिवशेन संततमहो पार्श्वे परिभ्राम्यति ॥ १ ॥

तत्र श्री**जंबूको** नाम बभूव सचिवाग्रणीः ।
यद्बुद्धि**गूर्जराधीश**राज्यलक्ष्मीरसायनम् ॥ २ ॥

अभूत्तदन्वयांभोधिसुधादीधितिसन्निभः ।
वीरः कुवलयानंदकंदकंदलनोद्यमी ॥ ३ ॥

शांतस्वांतस्ततो जातः श्री**शांतः** सचिवाग्रणीः ।
अंबिकाचरणांभोजभृंगी तस्याऽऽ**म्बडा** प्रिया ॥ ४ ॥

अजायत ततः श्रीमान् **विमलो** नाम नंदनः ।
येनाखिलं कुलं चक्रे विमलं विमलात्मना ॥ ५ ॥

आसी**ल्लक्ष्मी**रिति ख्याता प्रथमा तस्य गेहिनी ।
अपरा **रुक्मिणी** नाम्ना धर्मकर्मसु कर्मठा ॥ ६ ॥

लक्ष्मीकुक्षिसरोहंसः स्वकुलोत्तंसतां गतः ।
अजायत सुतस्तस्य **यशोदेवा**भिधः सुधीः ॥ ७ ॥

बभूव सत्पथे पांथः **पेथाक** इति विश्रुतः ।
तदन्यो **रुक्मिणी**कुक्षिसुक्तिमुक्तामणिः सुतः ॥ ८ ॥

यशोदेवोऽस्य सत्कर्मारामपीयूषसारणिः ।
प्रत्युः पदांतिके लीना **केली**नाम्नाऽजनि प्रिया ॥ ९ ॥

तत्सूनुर्जिनधर्मवारिधिविधुर्दाक्षिण्यपण्यापणः
श्रीसंवासनवांबुजं विजयते **बीजाक** इत्याख्यया ।
श्लाघ्यं येन न केवलं निजकुलं कौलीनवंध्यात्मना
राज्यं **वीसल**भूपतेरपि परं माहात्म्यमारोपितम् ॥ १० ॥

आरामस्थितिविदुषा येनाऽयं **मल्लवासका**रामः ।
संवर्द्धितः सितयशः कुसुमैर्व्यवहारिभिः फलदैः ॥ ११ ॥

मोहिनी जयति तस्य गेहिनी देहिनीव निजमंदिरेंदिरा ।
नंदनश्च **घटसिंह**संज्ञया ज्ञातिलोककुमुदैकचंद्रमाः ॥ १२ ॥

संग्रामसिंहनामा कुलकमलरविश्च तदनुजो विजयी ।
खेतू-पातू-पेथूनाम्न्यस्तिस्रो दुहितरश्च ॥ १३ ॥

तदेवधरो **देवधरो**ऽजनि पिता च **मोहिन्याः** ।
जननीसौजन्यामृत न वालुका वालुक........... ॥ १४ ॥

मोहिन्या **मलधारि**गच्छमलयश्रीखंडशाखावतः
सच्छायां **नरचंद्र**सूरिसुगुरोरासाद्य सद्देशनाम् ।
...........हृदयप्रसत्तिमुचितामुद्धर्तुमाविष्कृतः
सोऽयं **पांडववृत्तपुस्तक**मिषान्मूर्त्तः प्रमोदो बभौ ॥ १५ ॥

दिग्दंतावलदंतमंडलगुरुस्तंभाग्रजाग्रत्कर-
श्रेणीसूत्रिततोरणेऽम्बरलसन्निस्तंद्रचंद्रोदये ।
भास्वद्दीपकुलाद्रिमंडनधरे रोदःपुटीमंडपे
भूयात् पुस्तक एष शाश्वतसुधासत्रं पवित्रात्मनाम् ॥ १६ ॥ छ ॥

*

No. 222: Sudarśanācaritra **सुदर्शनाचरित्र**

Folios – 232 Size – 12.2 × 1.7 inches
Language – Prakrit Condition – Fair
Age of MS. – c. Latter half of 13th cent. V.S.
General Remarks – Several folios are bitten by mice on one side. The closing lines have been rubbed off. The *Praśasti*-folio is missing. This work is different from the Sudarśanācaritra composed by Devendrasūri.

*

No. 223 : (1) Aṣṭaprakārīpūjākathā—from Anantanāthajinacarita

(१) अष्टप्रकारीपूजाकथा—अनन्तनाथजिनचरितान्तर्गता

Folios – 1-152
Language – Prakrit
Author – Nemicandrasūri
Extent – Gāthās 1525
Size – 14 × 1.5 inches
Condition – Good
Age of MS. – c. First half of 14th cent. V. S.
General Remarks – Folios 82–85, 113, 114, 116, 117, 121, 123, 125, 133, 135, 140–144 & 152 missing.

आदि—

॥ ॐ नमः सर्वज्ञाय ॥

जयइ जुगाइजिणिंदो परिविलसिरसमवसरणचउरूवो ।
वागरिउं पिव सुहदाण-सील-तव-भावणाधम्मो ॥
सो जयइ जिणोऽणंतो देसणदसणंसुणो सया जस्स ।
केवलरविकिरणा इव तममवणिंता वियंभंति ॥ २ ॥
सिरिवद्धमाणसामिं नमामि कणयाभदेहदित्तीए ।
कुणमाणं पिव भुवणं सव्वं पि हु अत्तणो तुल्लं ॥ ३ ॥

(2) Mitrasenākathā (२) मित्रसेनाकथा

Folios – 153–178
Language – Prakrit
Size – 14 × 1.5 inches
Condition – Good
Age of MS. – c. First half of 14th cent. V. S.
General Remarks – Folios 153, 155, 163, 164, 168, 170, 171, 173, 176, 177 missing.

अन्तः—

मित्तसेणा वि य गणणीए समप्पिया । तओ सा ताण सामीवे सामाइयमाइगाणि अंगाणि अहिज्जिया । इमो य **मंजरिदत्तो** से सुओ साहुसमाणधम्मं करेइ । सव्वाणि ताणि सामन्नमणुपालेऊण सुरलोयं गयाणि । तओ सुहपरंपराए सिद्धिं गच्छिस्संति ॥ छ ॥ **मेत्तसेणा कथा समाप्ताः** ॥ छ ॥ मंगलं महाश्रीः ॥ शुभं भवतु लेखकपाठकयोः ॥

(3) Rājahaṃsakathā (३) राजहंसकथा

Folios – 178–209
Language – Sanskrit
Size – 14 × 1.5 inches
Condition – Good
Age of MS. – c. First half of 14th cent. V. S.
General Remarks – Folios 179, 183–185, 187, 193, 195 missing.

आदिः—

वयस्य ! विश्रुतो **राजहंसः** किं न पुनस्त्वया ? ।
स्वल्पस्यापि सकृद्भंगे व्रतस्यापन्महारुजाम् ॥ १ ॥
आकर्णय सकर्ण ! त्वं **राजहंसकथा**मिमाम् ।
संक्षेपादेष आख्यामि व्रतभंगफलं स्फुटम् ॥ २ ॥

*

No. 224: Pratyekabuddhakathā प्रत्येकबुद्धकथा

Folios – 112
Size – 13.5 × 1·7 inches
Language – Prakrit
Condition – Fair
Author – Tilakācārya
Age of MS. – c. End of 15th cent. V.S.
General Remarks – Incomplete.

*

No. 225: Śālibhadracaritra Padya with Ṭippaṇī

शालिभद्रचरित्र पद्य टिप्पणीसह

Folios – 147
Extent – Granthas 1224
Language – Sanskrit
Size – 12.2 × 2 inches
Author – Dharmakumāra
Condition – Good
Age of MS. – c. Latter half of 14th cent. V. S.
General Remarks – Folio 23 missing
Date of Composition – 1334 V.S.

आदिः—

॥ ॐ नमः श्रीसर्वज्ञाय ॥ अर्हं ॥

श्रीदानधर्मकल्पद्रुर्जीयात् सौभाग्यभाग्यभूः ।
पूर्वा-ऽपश्चिमतीर्थेशलक्ष्मीभोगमहाफलः ॥ १ ॥

अन्तः—

ब्राह्मी निर्मलशब्दसिद्धिकलिता मन्ये पवित्रशया
लक्ष्मीर्वा पुरुषोत्तमप्रियतमा नानार्थजातप्रसूः ।
उद्यन्मङ्गल**शालिभद्र**चरिता गौरी गिरीशप्रिया
जीयाद्ध**र्मकुमार**पंडितमतिर्विस्तारिधर्मोन्नतिः ॥ ५८ ॥

॥ इति **शालिभद्रचरिते** सर्वार्थसिद्धिवर्णनो नाम सप्तमः प्रस्तावः समाप्तः ॥ छ ॥

जिनातिशययक्षाख्य १३३४ वत्सरे विहिता कथा ।
ग्रन्थेन द्वादशशती चतुर्विंशतिसंयुता ॥ छ ॥

*

No. 226 : (1) Śālibhadracaritra : (१) शालिभद्रचरित्र

Folios – 24
Extent – Gāthās 177
Language – Prakrit
Size – 8·5 × 2 inches
Age of MS. – c. Latter half of 13th cent V. S.
Condition – Good
General Remarks – Folios 11–17 missing.

(2) Sukośalākhyānaka : (२) सुकोशलाख्यानक

Folios – 25–44
Extent – Gāthās 101
Language – Prakrit
Size – 8.5 × 2 inches
Age of MS. – c. Latter half of 13th cent. V.S.
Condition – Good
General Remarks – Folios 29, 38 missing.

(3) Subāhucaritra : (३) सुबाहुचरित्र

Folios – 45–79
Extent – Gāthās 228
Language – Prakrit
Size – 8.5 × 2 inches
Age of MS. – c. Latter half of 13th cent. V.S.
Condition – Good

(4) Ajitaśāntistava : (४) अजितशान्तिस्तव

Folios – 79–88
Extent – Gāthās 41
Language – Prakrit
Size – 8.5 × 2 inches
Author – Nandiṣeṇa
Condition – Good
Age of MS. – c. Latter half of 13th cent. V.S.

(5) Pāpapratighātaguṇabījādhānasūtra :
(५) पापप्रतिघातगुणबीजाधानसूत्र

Folios – 88-93
Size – 8.5 × 2 inches
Language – Prakrit
Condition – Good
Age of MS. – c. Latter half of 13th cent. V.S.

*

No 227 : Dhammillacaritra Prose & Verse
धम्मिल्लचरित्र गद्य-पद्य

Folios – 10-88
Size – 12 × 2 inches
Language – Prakrit
Condition – Good
Age of MS. – c. Beginning of 12th cent. V.S.
General Remarks – More than 50% of the folios towards the close represent fresh writing on paper in c. 14th & 15th cent. V.S. These new ones are spoiled, while the original palm-leaves of the ms. are in very good condition. The mode of writing and the hand-writing also are very nice.

*

No. 228 : Dānādiprakāśa दानादिप्रकाश

Folios – 43–117 Size – 12 × 2 inches
Language – Prakrit Condition – Good
Age of MS. – c. First half of 13th cent. V.S.
General Remarks – Very nice writing. Incomplete,

*

No. 229 : (1) Naradevakathā—On Generosity

(१) नरदेवकथा—दाने

Folios – 3–21 Size – 13 × 2.5 inches
Language – Prakrit Condition – Good
Age of MS. – c. Latter half of 14th cent. V.S.

(2) Ratisundarīmahāsatīkathānaka—On Chastity

(२) रतिसुंदरीमहासतीकथानक—शीलव्रते

Folios – 22–40 Size – 13 × 2.5 inches
Language – Prakrit Condition – Good
Age of MS. – c. Latter half of 14th cent. V.S.

(3) Rohiṇīcaritra—on Penance

(३) रोहिणीचरित्र—तपोविषये

Folios – 40–150 Extent – Up to 1003 Gāthās
Language – Prakrit Size – 13 × 2.5 inches
Age of MS. – c. Latter half of 14th cent. V.S. Condition – Good
General Remarks – Slightly incomplete.

*

No. 230 : Dharmābhyudayamahākāvya—Saṅghapativastupālacaritra

धर्माभ्युदयमहाकाव्य—संघपतिवस्तुपालचरित्र

Folios – 385 Extent – 5041 Grānthas
Language – Sanskrit Size – 17.7 × 2.2 inches
Author – Udayaprabhasūri Condition – Good
Age of MS. – 1290 V.S.
General Remarks – This ms. is written by Minister Vastupāla himself in 1290 V.S. and as such it is very valuable. The last folio indicating the hand-writings of Minister Vastupāla is dilapidated and it is kept as a separate ms. It should be very carefully preserved.

अन्तनो उल्लेख—

॥ छ ॥ उभयं ५०४१ ॥ छ ॥ सं० १२९० वर्षे चैत्र शु. ११ रवौ **स्तंभतीर्थ-वेलाकुलमनुपालयता** महं० श्रीवस्तुपालेन श्री**धर्माभ्युदयमहाकाव्य**पुस्तकमिदमलेखि ॥ छ ॥

No. 231 : Dharmābhyudayamahākāvya—Saṅghapativastupālacaritra

धर्माभ्युदयमहाकाव्य—सङ्घपतिवस्तुपालचरित्र

Folios – 381
Extent – Grānthas 5200
Language – Sanskrit
Size – 17.5 × 1.7 inches
Author – Udayaprabhasūri
Condition – Good
Age of MS. – c. Beginning of 14th cent. V.S.

*

No. 232 : Kahārayaṇakosa—Kathāratnakośa

कहारयणकोस—कथारत्नकोश

Folios – 317
Size – 31 × 2.2 inches
Language – Prakrit
Condition – Good
Author – Devabhadrasūri
Date of Composition – 1158 V.S.
Age of MS. – 1286 V.S.
General Remarks – The Praśasti at the close of the work is rubbed off. The quotation here, however, is based on what little can be deciphered out of it.

आदिः—

॥ ॐ नमो जिनागमाय ॥

पडिबिंबियपणयजणा निलीणभवभीरुभव्वलोय व्व ।
उम्मुहमऊहनिवहा सिवभवणारोहसेणि व्व ॥ १ ॥

भीमभवोयहिलंघणसज्जा सज्जाणवत्तपंति व्व ।
चरणनहमालिया सहइ जस्स सो जयइ पढमजिणो ॥ २ ॥

सुमणोऽभिरामरूवो चारुपओ सुरहिवयणसयवत्तो ।
जयइ सिवनयरिपत्थियमंगलकलसो व्व **वीरजिणो** ॥ ३ ॥

स जयइ पुणो वि दुज्जयकसायसरहोलिविहलिउच्छाहो ।
लंछणछलेण भीउ व्व केसरी जं समल्लीणो ॥ ४ ॥

भवचारयबंधं बंधुणो व्व अवणिंतु वोऽवसेसा वि ।
जिणवइणो मोहमहंधयारहरणम्मि रविणो व्व ॥ ५ ॥

पासस्स फणामणिणो उम्मुहपसरंतकंतिणो दूरं ।
विहियावट्टियदीवूसव व्व तिमिरं हरंतु ममं ॥ ६ ॥

जयइ विलसंतनिम्मलमऊहमंडलपसाहियसरीरा ।
पग्गहियपारिवेस व्व ससिकला भयवई वाणी ॥ ७ ॥

ससिरीया सच्चाहिट्टिया य सच्चक्कनंदया सुगया ।
गुरुणो हरिणो व्व कुणंतु वंछियं निच्छियं मज्झ ॥ ८ ॥

इत्थं थोयव्वथुईसामत्थेणं जडो वि जंपेमि ।
सम्मत्ताइपयत्थप्पडिबद्ध**कहारयणकोसं** ॥ ९ ॥

अन्तः—

पन्नासऽत्थनिबद्धो एस समप्पइ **कहारयणकोसो** ।
जत्तो समुट्ठिओ पुण एसो तं इण्हि निसुणेह ॥

चंदकुले गुणगणवद्धमाणसिरि**वद्धमाण**सूरिस्स ।
सीसा **जिणेसरो बुद्धिसागरो** सूरिणो जाया ॥

तह कह वि संजमभरो उव्वूढो जेहिं धीरधवलेहिं ।
अज्झवसिउं पि तीरइ जह अज्ज वि नेव केहिं पि ॥

ताण **जिणचंद**सूरी सीसो सिरि **अभयदेव**सूरी वि ।
रवि-ससहर व्व पयडा अहेसि सियगुणमऊहेहिं ॥

तेसिं अत्थि विणेओ समत्थसत्थत्थपारपत्तमई ।
सूरी **पसन्नचंदो** न नामओ अत्थओ वि **परं** ॥

तस्सेवगेहिं सिरि**सुमइवायगाणं** विणेयलेसेहिं ।
सिरि**देवभद्द**सूरीहिं एस रइओ **कहाकोसो** ॥

संघधुरंधरसिरि**सिद्ध-वीर**सेट्ठीण वयणओ जेहिं ।
चरियं चरिमजिणिंदस्स विरइयं **वीरनाहस्स** ॥

परिकम्मिऊण विहियं च जेहिं सइभव्वलोगपाओग्गं ।
संवेगरंगसालाभिहाणमाराहणारयणं ॥

कंचणकलसविहूसिय**मुणिसुव्वयभवण**मंडियम्मि पुरे ।
भरुयच्छे तेहिं ठिएहिं एस नीओ परिसमत्तिं ॥

वसुबाणरुद्दसंखे ११५८ वच्चंते विक्कमाओ कालम्मि ।
लिहिओ पढमम्मि य पोत्थयम्मि गणि अमलचंदेण ॥

अलं बहुभणिएण ।

यदिह जगदे किंचिन्मोहाद् मया समयाद्बहि-
र्यदपि सुकविक्षुण्णान्मार्गाद्वचोऽभिदधेऽन्यथा ।
तदुदितकृपैः सद्भिस्त्यक्त्वा तथैष विशोध्यताम् ।
भवति **कथिकाकोशः** पंथा यथा शिवसद्मनः ॥ १ ॥

यत्कृत्वेदं त्रिकरणजयात् पुण्यमस्माभिराप्तं
तेनैवैतच्छ्रवणपठनाख्यानचिंतैकचित्ताः ।
संतः संतु प्रतिसभमितश्चाप्तमोहव्यपोहा
भूयो भूयो जिनपतिमते बोधिसिद्धिं लभंताम् ॥ २ ॥

जीयासुः शशिनीलकांचनजपामेघोपमांगत्विषः
श्रीमन्नाभितनूद्भवप्रभृतयः सर्वेऽपि तीर्थेश्वराः ।
गीरम्बा च **सुदर्शना** च विदिता देव्योऽपि **काल्यादयो**
भूयासुर्जिनशासनस्य सततं प्रोत्सर्पणाहेतवे ॥ ३ ॥

इति बहुविधवाक्यानेकमाणिक्यपूर्णागमजलनिधिलब्धैरर्थलेशैर्निबद्धः ।
तदपि निहतभूतिप्राणिदौर्गत्यदुःखो जयतु सततमेष **श्रीकथारत्नकोशः**
॥ छ ॥ ४ ॥

इति प्रव्रज्यार्थचिंतायां **श्रीप्रभप्रभाचंद्रचरितमुक्तं** । तदुक्तौ च सम्यक्त्वादिपंचाशदर्थाधिकारसंबद्धः **कथारत्नकोशो**ऽपि समाप्तः ॥ छ ॥ मंगलं महाश्रीः ॥ शुभं भवतु ॥

शिवमस्तु सर्वजगतः परहितनिरता भवंतु भूतगणाः ।
दोषाः प्रयांतु नाशं सर्वत्र सुखी भवतु लोकः ॥ छ ॥

सं. १२८६ वर्षे श्रावण शुदि २ बुधेऽद्येह **प्रल्हादनपुरे कथारत्नकोशपुस्तकमलेखीति** भद्रमिति ॥ छ ॥

*

No. 233 : Ākhyānakamaṇikośa with Commentary

आख्यानकमणिकोश—सटीक

Folios – 483
Language – Prakrit, Sanskrit, Apabhraṃśa
Author – Nemicandrasūri
Commentator – Āmradevasūri
Age of MS. – c. First half of 13th cent. V. S.

Extent – Granthas 14000
Size – 30.2 × 2.2 inches
Condition – Good
Date of Compositon of commentary – 1199 V.S.

आदि—

॥ ॐ नमः सर्वज्ञाय ॥

स्वर्नाथभीतघनभूधरसेव्यमूर्त्तिर्लावण्यधामबहुधीवरलब्धमध्यः ।
आख्यानकाख्यमणिकोशमहार्घरूपो जीयाद् **युगादिजिन**नायकनीरनाथः ॥ १ ॥

सिद्धार्थपार्थिववरान्वयलब्धजन्मा निर्मिथ्यवीरवलयान्वितरम्यमूर्तिः ।
रागादिशत्रुगुरुविक्रमवर्ण्यवर्णो जीयाज्जगत्त्रयजयासमवेश्म **वीरः** ॥ २ ॥

राकाशशांककरनिर्मलकीर्त्तिभाजो ज्ञानादिरत्नचयरोहणशैलकल्पाः ।
शेषा अपि प्रणतकल्पितकल्पवृक्षा जीयासुरानतसुरप्रभवो जिनेन्द्राः ॥ ३ ॥

श्री**गौतम**मुनिमुख्याः श्रुतजलधिविचारपारगतवचसः ।
सुगृहीतनामधेया जयंतु **गणधारिणः** सर्वे ॥ ४ ॥

यस्याः प्रसादमासाद्य सद्यः संजायते पुमान् ।
पारगामी श्रुताम्भोधेः स्तौम्यहं तां **सरस्वतीम्** ॥ ५ ॥

अस्मादृशा अपि विशिष्टविवेकशून्या येषां प्रसादमधिगम्य मनीषिमान्याः ।
जाताः परोपकरणप्रकृतिप्रवीणास्तानप्यचिंत्यमहसः स्वगुरून् प्रणौमि ॥ ६ ॥

इत्थं कृतनमस्कारो ध्वस्तविघ्नविनायकः ।
विधास्ये विधिनाऽऽरब्धं समीहितमहं सुखम् ॥ ७ ॥

इहानंतजन्मजरामरणप्रवाहपयःपूरपूरिते इष्टवियोगानिष्टसंप्रयोगव्यसनशतकल्लोलमाला-समाकुले हर्षविषादाद्यनेकप्रकारप्राणिपरिणामपरंपरारंगत्तरंगे शारीरमानसानेककटुकदुःख-दुष्टश्वापदसमाकीर्णे भुवनत्रयसंतापसंपादनपटिष्ठप्रकृतिप्रज्वलन्मदनवडवानले अनंतभवभ्रमण-निमित्तदुरंतकषायमहापातालकलशालये अनुपलब्धपरपारसंसारपारावारे निमज्जता भव्यजंतुना कर्णधारादिसमग्रसामग्रीकं यानपात्रमिव जलधिजलमध्यपतितरत्नमिवातिदुर्लभं लब्ध्वा श्रीसर्वज्ञप्रणीतधर्मान्वितं मनुजजन्म परोपकारे यतितव्यम् । स चोपकारो यद्यपि द्रव्यादिभेद-भिन्नत्वेनानेकप्रकारस्तथापि जिनवचनोपदेशेन भावोपकारेणोपकर्त्तव्यम् । तस्यैकांति-कात्यंतिकरूपत्वादितरस्य चानैकांतिकानात्यंतिकस्वरूपत्वात् । जिनवचनोपदेशोऽप्युपदेष्टव्य-भेदादनेकप्रकारोऽतो धर्मकथारूपोपदेशेनैव भव्यानामुपकर्त्तव्यम् । तेषामज्ञातधर्मस्वरूपाणां धर्मतत्त्वप्रकाशनेन तस्य महोपकारित्वात् । अतो भव्यानुपचिकीर्षुः श्रीम**न्नेमिचंद्र**

सूरिर्धर्मकथास्वरूपम**आख्यानकमणिकोश**मेकचत्वारिंशदधिकारसमन्वितं विरचितवान्, **तस्य** विवरणं प्रस्तूयते । तस्य चादावेव मंगलाभिधेयप्रयोजनप्रतिपादिकेयं गाथा ॥

> नमिऊण जिणं **वीरं** सुरमहियं केवलिं पवरवाणिं ।
> **अक्खाणयमणिकोसं** भव्वजणविबोहयं वोच्छं ॥

अन्तः—

इदानीं शास्त्रकारः शास्त्रवक्तव्यतामुपसंहरन् शास्त्रगतपठनादिफलं च दिदर्शयिषुरिदमाह—

> **अक्खाणयमणिकोसं** एयं जो पढइ कुणइ जहजोग्गं ।
> **देविंदसाहु**महियं अइरा सो लहइ अपवग्गं ॥

व्याख्या । **अख्यानकमणिकोशं** व्यावर्णिताभिधेयं एतं पूर्वोक्तस्वरूपं 'जो पढइ' यः पुण्यवान् पठति व्यक्तं कंठे धारयति, करोति विधत्ते यथायोगमौचित्याराधनेन । **देवेन्द्र**साधुमहितं सुरपतिमुनिपूजितम्, अपवर्गविशेषणमिदं । अचिराच्छीघ्रमेव स जीवो लभते प्राप्नोत्यपवर्गं मोक्षमिति गाथाक्षरार्थो भावार्थस्त्वत्रापि गाथायां देवेन्द्रेति साध्ववस्थायां निजनाम विशेषणमध्ये विराचितमिति । **कृतिरियं सैद्धांतिकशिरोमणिश्रीमन्नेमिचन्द्रसूरेरिति । आख्यानकमणिकोशवृत्तिः समाप्ता ॥**

> वृत्तिं विधाय यदिमां महतीं मयाऽऽप्तं
> पुण्यं पवित्रितजगत्त्रयचित्तवृत्ति ।
> तेनाऽऽशु भव्यनिवहो लभतां भवाब्धौ
> सद्यानपात्रमिव बंधुरबोधिबीजम् ॥ छ ॥

> ज्ञानादिरत्नवसतिर्जनमान्यलक्ष्मीजन्माग्रभूमिरभितो बहुसत्त्वसेव्यः ।
> निर्द्धौतकर्ममलनिर्मलधर्मनीरः क्षोणीभृदाश्रितगरिष्ठगभीरमध्यः ॥ १ ॥

> अच्युतप्रवणावासो मर्यादानतिवर्त्तकः ।
> अस्ति स्वच्छो **बृहद्गच्छः** श्रीमान्नाथ इवांभसाम् ॥ २ ॥

> इति नीरधितुल्यगुणे दयासुधापास्तजन्मरुग्मरणे ।
> क्वचिदतिशायिनि समये शिष्टा निशमयत यज्जातम् ॥ ३ ॥

> मुनिविबुधधृतजिनमतमंदरमथिमथ्यमानतन्मध्यात् ।
> स्फूर्जन्महाप्रभावः प्रादुरभूद् रम्यरत्नचयः ॥ ४ ॥

तथा हि—

श्रीदेवसूरिः सुमनःसमृद्धः समुल्लसत्सत्फलपत्रशाखः ।
कुतोऽप्यथो आविरभूदमुष्मात् सुरावगीतोपाचिपारिजातः ॥ ५ ॥

अनेकविकृतिक्रियाकुटिलकर्मरूपामयाऽपहारकरणक्षमः श्रुतिविचारदक्षः शुचिः ।
प्रवृद्धकरुणामृतस्समुदपादि धन्वंतरिः श्रियां पदमनागसा**मजितसूरि**रयं सताम् ॥ ६ ॥

रुचिरचरणयोगादुर्द्धरैरावतोऽभूदनुपममदवारिप्रोल्लसत्कीर्त्तिघंटः ।
प्रकटितसकलांगो मोहसैन्याप्रधृष्यो विबुधपतिनिषेव्यः श्री**मदानंदसूरिः** ॥७॥

समुन्नत्याधारः स्वरगतलसल्लक्षणधरः
श्रुतिश्रेयानंशिर्दधदपरचिह्नानि नितराम् ।
विनिर्यत्सद्धेतौ सुविषममहावादिसमरे
स्फुरत्तेजोद्दप्यत्तरलनयनोऽश्वश्च निरगात् ॥ ८ ॥

श्रीनेमिचन्द्रसूरिः यः कर्त्ता प्रस्तुतप्रकरणस्य ।
सर्वज्ञागमपरमार्थवेदिनामग्रणीः कृतिनाम् ॥ ९ ॥

अन्यां च सुखावगमां यः कृतवा**नुत्तराध्ययनवृत्तिम्** ।
लघुवीरचरितमथ **रत्नचूडचरितं** च चतुरमतिः ॥ १० ॥

शश्वत्पंडितमंडलीकुमुदिनीकांताप्रमोदावहः
सर्वज्ञागमदेशनामृतकरैर्निर्वापयन् मेदिनीम् ।
भास्वत्सन्मुनितारकेषु नियतं सन्नायकत्वं दधत्
स श्रीमानुदियाय यो निजकुलव्योमांगणालंकृतिः ॥ ११ ॥

सूरिः **श्रीजिनचंद्रश्चन्द्रो** निःशेषजनमनोदयितः ।
सौम्यत्वकलावित्त्वप्रभृतिगुणानां स्वकुलभवनम् ॥ १२ ॥

तच्छिष्यः प्रथमपदे श्रीपदवा**नाम्रदेवसूरि**रभूत् ।
अपरोऽपि तत्कनिष्ठः श्रीमान् **श्रीचंद्र**सूरिरभूत ॥ १३ ॥

इतश्च—

यो **मेदपाटा**ध्युषितोऽपि धीमान् दयाधनो धार्मिकमध्यवर्त्ती ।
सत्साधुताधर्मकृताभिलाषः सुश्रावकत्वं परिपाति सम्यक् ॥ १४ ।

मारावल्ल्या अल्लकश्रेष्ठिवर्यो मुक्त्वा स्वीयं धाम हेतोः कुतश्चित् ।
आयातोऽसावर्बुदाधःप्रदेशे तत्राप्यासीत् स्वैर्गुणैः सुप्रसिद्धः ॥ १५ ॥

किंच—

कासहृदधाम्नि निजं धर्म्यं धाम प्रवर्त्तितं येन ।
पोषधशाला सच्छ्रावकादिधर्मार्थमत्यर्थम् ॥ १६ ॥

आजन्माऽपि जिनेश्वरस्य सदने बिंबे जिनाभ्यर्चने
तीर्थानामभिवंदने जिनमतव्यालेखनेऽलंकृतौ ।
श्रीमत्सूरि-महत्तरापद-जनप्रव्राजनादौ शुभे
धर्मार्थं व्ययतो धनं सफलतां यस्यागमद्धीमतः ॥ १७ ॥

स सिद्धनागः .... सुलब्धजन्मा सदाकृतिर्धर्मविशुद्धकर्मा ।
पुत्रोऽभवत्तस्य जनप्रसिद्धः पुण्यानुभावाच्च सदा समृद्धः ॥ १८ ॥

तस्मादपि दौस्थित्यात् कुतोऽपि **धवलक्कके** समायातः ।
श्रेष्ठी स **सिद्ध**नामा तत्रापि जने गुणैः प्रथितः ॥ १९ ॥

अन्यच्च येन कारितमतिरम्यं भव्यजनमनोहारि ।
सीमंधरजिनबिंबं रमणीये **मोढचैत्यगृहे** ॥ २० ॥

त्यागी भोगी देवगुर्वादिभक्तो जैने धर्मे प्रेमरागानुरक्तः ।
वार्द्धक्येऽभूदेक **उद्योतना**ह्वः पुत्रस्तस्य त्यक्तदुष्टद्विजिह्वः ॥ २१ ॥

श्रीनेमिचंद्रसूरेर्वाक्यात्तदनु स्वशिष्यभणनाच्च ।
उद्योतनसच्छ्रावकविशेषसद्भक्तिवचनाच्च ।
तत्रैव **बृहद्गच्छे** रत्नाकरसन्निभे प्रसूतेन ।
प्राकृतमणिकल्पेन श्रुतगुरुबहुमानसहितेन ॥ २३ ॥

श्रीपदसंगतनाम्ना श्रीम**ज्जिनचंद्र**सूरिशिष्येण ।
रचिताऽऽ**म्रदेव**मुनिपेन वृत्तिरेषा स्वबोधेन ॥ २४ ॥

व्याख्याप्रज्ञप्ताविव लब्धवरायामिहापि सद्वृत्तौ ।
श्रुतिसुखदवर्णरुचिरा विचित्रगमभंगरमणीयाः ॥ २५ ॥

सुव्यक्तमेकचत्वारिंशदनूना भवेयुरधिकाराः ।
तत्र सतानी च विचारश्रुता अध्ययवृत्ताश्च(?) ॥ २६ ॥

सत्स्वपि नानारूपेषु पूर्वकविभिर्विशिष्टमतिविभवैः ।
रचितेषु शास्त्रविवरणकथाप्रबंधेषु सरसेषु ॥ २७ ॥

कीदृगिदं मत्काव्यं तदापि ग्राह्यं कृतप्रचुरकरणैः ।
मयि वल्लभमाध्यस्थ्ये माध्यस्थ्यगुणान्वितैः सद्भिः ॥ २८ ॥

छंदोलक्षणविकलं समयोत्तीर्णं च यत् किमपि लिखितम् ।
तच्छोध्यं विद्वद्भिः कृतांजलिः प्रार्थये भवतः ॥ २९ ॥

अन्यच्च **नेमिचंद्रा गुणाकराः पार्श्वदे**वनामानः ।
एते त्रयोऽपि गणयो विपश्चितो मुख्यनिजशिष्याः ॥ ३० ॥

साहाय्यं कृतवंतो मम लेखनशोधनादिकृत्येषु ।
आधानोद्धरणे च प्रमादविकलाः कलाकुशलाः ॥ ३१ ॥

नवत्या युक्तेषु प्रथितयशसो विक्रमनृपा-
च्छतेषु क्रांतेषु त्रिनयनसमानेषु शरदाम् ११९० ।
अजय्ये सौराज्ये जयति **जयसिंह**स्य नृपते-
रियं स्थानीयेऽगाद्**धवलकपुरे** सिद्धिपदवीम् ॥ ३२ ॥

श्रेष्ठि**यशोनाग**स्याऽऽरब्धा वसतावस्थितैः सद्भिः ।
वसतां सम्यगवसिता वसताव**च्छुप्त**सत्कायाम् ॥ ३३ ॥

भुवनानीव चतुर्दश धातुर्मम रम्यवर्णपदभाजि ।
अक्षरगणनाद् ग्रंथो जातोऽनुष्टुप्सहस्राणि ॥ ३४ ॥

मानसगर्भे स्थित्वा लक्षणयुगयं सपादनवमासैः ।
आख्यानकमणिकोशः सुत इव समपादि सद्वृत्तिः ॥ ३५ ॥

यावच्चंद्रश्च सूर्यश्च यावन्मेरुर्महीतलम् ।
स्वर्गापवर्गवत्तावन्नंद्यादेषाऽपि मत्कृतिः ॥ ३६ ॥ ग्रंथाग्रं १४००० ॥छ॥

इति श्रीमद्रामदेवसूरिविरचितवृत्तावाख्यानकमणिकोशवृत्तिः समाप्तेति ॥ छ ॥ मंगलं महाश्रीः ॥ छ ॥

शिवमस्तु सर्वजगतः परहितनिरता भवंतु भूतगणाः ।
दोषाः प्रयांतु नाशं सर्वत्र सुखी भवतु लोकः ॥ छ ॥

प्राग्वाटवंशतिलकोऽजनि पूर्णदेवस्तस्यात्मजास्त्रय इह प्रथिता बभूवुः ।
दुर्वारमारकरिकुंभविभेदसिंहस्तत्रादिमः **सलखणो**ऽभिधया **बभूव** ॥ १ ॥

द्वितीयकोऽभूद् **वरदेव**नामा तृतीयकोऽभूज्जिन**देव**संज्ञः ।
सोऽन्येद्युरादत्त जिनेन्द्रदीक्षां निर्वाणसौख्याय मनीषिमुख्यः ॥ २ ॥

अज्ञानध्वांतसूर्यः सरभसविलसच्चंगसंवेगरंग-
क्षोणी क्रोधादियोधप्रतिहतिसुभठो ज्ञातनिःशेषशास्त्रः ।
निर्वेदांभोधिमग्नो भविककुवलयोद्बोधनाधानचंद्रः
कालेनाऽऽचार्यवर्यः स समजनि **जगच्चंद्र** इत्याख्यया हि ॥ ३ ॥

वरदेवस्य संजज्ञे **वाल्हेवि**रिति गेहिनी ।
याऽभूत् सदा जिनेंद्रांह्रिकमलासेवनेऽलिनी ॥ ४ ॥

पुत्रास्तयोः **साढलनामधेया-ऽरिसिंहइ**त्याह्वय**वज्रसिंहाः** ।
विवेकपात्री **सहजू** च पुत्री कुशीलसंसर्गतरोर्लवित्री ॥ ५ ॥

साढलस्य प्रिया जज्ञे **राणू**रिति महासती ।
पुत्रास्तु पंच तत्राद्यो **धीणा**ख्यः शुद्धधर्मधीः ॥ ६ ॥

द्वितीयः **क्षेमसिंहा**ख्यो **भीमसिंह**स्तृतीयकः ।
देवसिंहाभिधस्तुर्यो लघु**र्महणसिंहकः** ॥ ७ ॥

क्षेमसिंहाभिधो **देवसिंह**श्च भवभीरुकः ।
श्रीजगच्चंद्रसूरीणां पार्श्वे व्रतमशिश्रियत् ॥ ८ ॥

धीणाकस्य कडूर्नाम पत्नी **मोढा**भिधः सुतः ।
अन्येद्युः सुगुरोर्वाक्यं **धीणाकः** श्रुतवानिति ॥ ९ ॥

भोगास्तुंगतरंगभंगभिदुराः संध्याभ्ररागभ्रमी-
पम्या श्रीर्नलिनीदलस्थितपयोलोलं खलु प्राणितम् ।
तारुण्यं तरुणीकटाक्षतरलं प्रेमा तडित्सन्निभो
ज्ञात्वैवं क्षणिकं समं विदधतां धर्मं जनाः ! सुस्थिरम् ॥ १० ॥

सज्ज्ञानयुक्तो नियतवृषोऽपि भवेन्महानंदपदप्रदायी ।
तत्रापि च स्वाऽन्यविबोधकारीत्याहुः श्रुतज्ञानमिहोत्तमं हि ॥ ११ ॥

तच्च कालमतिमांद्यदोषतः पुस्तकेषु भुवनैकवत्सलैः ।
पूर्वसूरिभिरथो निवेशितं तद् वरं भवति तस्य लेखनम् ॥ १२ ॥
एवं निशम्य तेन न्यायोपार्जितधनेन धन्येन ।
आख्यानकमणिकोशस्य पुस्तकोऽयं व्यधायि मुदा ॥ १३ ॥
यावद्दारुणदुःखलक्षजलदप्रध्वंसचंडानिलो
रागद्वेषमदांधसिंधुरहरिः स्वर्गापवर्गप्रदः ।
अज्ञानद्रुमपावको विजयते श्रीजैनराजागम-
स्तावन्नंदतु पुस्तकोऽयमनिशं वावच्यमानो बुधैः ॥ १४ ॥
मंगलं महाश्रीः ॥ छ ॥

*

No. 234 : Upadeśamālākathākośa

उपदेशमालाकथाकोश

Folios – 152
Language – Prakrit
Author – Jinabhadrasūri
Age of MS. – c. Latter half of 13th cent. V. S.
Extent – Gāthās 2890 ; Granthas 3613
Size – 12.5 × 2.5 inches
Condition – Fair
Date of Composition – 1232 V.S.

General Remarks – Folios 2, 9-16, 22, 25, 31, 37, 38, a piece of 39, 54, 60, a piece of 62, 63, 65, a piece of 66, 67, 68, a piece of 69, 74-77, 79, 81, 94, 125, 130, a piece of 132 are missing. Thus in all 35 folios are missing—of which pieces of 5 folios are preserved.

आदिः—

अरहंतमरिहमरुहं पणमिय सिरिवीरवद्धमाणजिणं ।
संखेवेणं वुच्छं कहाउ उवएसमालाए ॥ १ ॥

अन्तः—

जमालिकथा ॥ छ ॥

नीसेसभुवणपंडियसिरोमणी जयउ धम्मदासगणी ।
उवएसमालकारी सिस्सो सिरिवीरनाहस्स ॥ १ ॥
उवमिइभवप्पवंचाकहा कया जेण निरुवमा लोए ।
विवरणकारस्स सया तस्स नमो सिद्धसूरिस्स ॥ २ ॥
सुगुरुगुणरयणसायरसिरि........गसूरिसिस्साणं ।
सुयचरणपवरसिरिसालिभद्दसूरीण सिस्सेहिं ॥ ३ ॥

सिरिजिणभद्दमुणिंदेहिं सुहयरो विवरणाणुसारेणं ।
उवएसमालपगरणकहासमासो कओ एस ॥ ४ ॥

बत्तीसाहियबारसवरिससएसुं १२३२ गएसु विक्कमओ ।
निप्फन्नो सुच................य आणंदगणिस्स साहिज्जा ॥ ५ ॥

गाहाण दो सहस्सा इह अट्ठ सयाणि नवइसहियाणि ।
तिन्नि सहस्सा छ सया तेरसअहिया सिलोगाणं ॥ ६ ॥

एयं पढंति अभिओगजुया गुणंति जाणंति जे उवइसंति परेसि सम्मं ।
जे वा सुणंति हिययंमि विभावयंति तेसिं हविज्ज अभिवंछियधम्मसिद्धी ॥७॥

मंगलं महाश्रीः ॥

दुव्वारमोहतिमिरप्पसरं हरंतो, सूरु व्व विप्फुरइ जाव जयंतरिक्खे ।
धम्मो जिणिंदभणिओ गयसव्वदोसो, कोसो कहाणमिह नंदउ ताव एसो ॥८॥

*

No. 235 : Pañcamīkathāsaṅgraha — **पंचमीकथासंग्रह**

Folios – 144
Language – Prakrit
Author – Maheśvarasūri
Age of MS. – 1214 V. S.

Extent – Gāthās 2000
Size – 15.7 × 2 inches
Condition – Good

आदिः—

॥ ॐ नमो वीतरागाय ॥

पंचिंदियनिरवेक्खं पंचनमोक्कारहेउयं तह य ।
पंचमगइसाहणयं पंचमनाणं नमंसेउं ॥

दुविहाए पंचमीए कालं पुरिसं विहाणगहणं च ।
पंचमितवफलभावं गाहाहिं महेसरो भणइ ॥

सक्कयकव्वस्सऽत्थं जेण न जाणंति मंदबुद्धीया ।
सव्वाण वि सुहबोहं तेणेयं पाइयं रइयं ॥

अंतः—

दोपक्खुज्जोयकरो दोसासंगेण वज्जिओ अमओ ।
सिरिसज्जणउज्झाओ अउव्वचंदो व्व अक्कत्थो ॥

सीसेण तस्स कहिया दस वि कहाणा इमे उ पंचमिए ।
सूरिमहेसरएणं भवियाणं बोहणट्ठाए ॥

सद्दगयं अत्थगयं जं किं पि वि दूसणं मए रइयं ।
तं सव्वं विउसेहिं खमियव्वं सोहियव्वं च ॥

विरयंतेणं एयं जं कम्मं अज्जियं मए सुहयं ।
तेण जणो मलरहिओ सव्वो वि महेसरो होउ ॥

मिलियाणं च दसाण वि एत्थ कहाणाण होइ विन्नेयं ।
गाहाणं माणेणं दोण्णि सहस्साइं गंथग्गं २००० ॥ छं ॥

इति महेश्वरसूरिविरचितं पंचमीफलमाहात्म्यसंसूचकं भविष्यदत्ताख्यानकं समाप्तम् ॥ छ ॥

यादृशं पुस्तके दृष्टं तादृशं लिखितं मया ।
यदि शुद्धमशुद्धं वा मम दोषो न दीयते ॥ छ ॥

मंगलं महाश्रीः ॥ संवत् १२१४ वर्षे मार्ग० शुदि ५ शुक्रे ॥ छ ॥

*

No. 236 : Nāgakumāracaritra–Pañcamīmāhātmya Padya of Five Sargas

नागकुमारचरित्र—पंचमीमाहात्म्य पद्य पंचसर्गात्मक

Folios – 14
Language – Sanskrit
Author – Ratnayogīndra-Digambara
Age of MS. – c. 14th cent. V. S.
Extent – Granthas 500
Size – 15.7 × 2.5 inches
Condition – Fair

आदिः—

॥ ॐ नमः सिद्धेभ्यः ॥

श्रीमान् व्यवहितारोऽपि वृतिं धर्मरथस्य यः ।
चक्रे चांतेर्विनाक्रांतस्तं नेमीनं नमाम्यहम् ॥

अथ दिग्वसनांभोजमंडनेन मनोमुदम् ।
प्रतन्वता प्रसादेन सहसा लब्धजन्मना ॥

द्युसद्दुंदुभिनादेन नभस्तलविसर्पिणा ।
दिव्यगंधभरेणेव मंडपस्थानवायुना ॥

अंतः—

ततोऽसौ श्रेणिकः श्रीमान् नत्वा त्रैलोक्यपूजितम् ।
देवं श्रीवर्द्धमानाख्यमगमत् स्वास्पदं मुदा ॥

श्रीपंचम्युपवासस्य फलोदाहरणात्मकम् ।
एवं नागकुमारस्य समाप्तिं चरितं ययौ ॥ छ ॥
इति श्रीरत्नयोगींद्रेणोपसंहृत्य कीर्त्तितम् ।
सहस्रार्द्धमितग्रंथमेतच्चरितमुच्चकैः ॥

इति नागकुमारचरिते श्रीपंचमीमहोपवासफलोदाहरणे पंचमः सर्गः ॥ मंगलं महाश्रीः ॥

*

No. 237 : (1) Siddhahemaśabdānuśāsanasūtrapāṭha upto Adhyaya VIII
(१) सिद्धहेमशब्दानुशासनसूत्रपाठ अष्टमाध्यायपर्यन्त

Folios – 97
Language – Sanskrit
Author – Hemacandrācārya
Size – 15 × 2 inches
Condition – Good
Age of MS. – 1293 V. S.

अन्तः—

शेषं संस्कृतवत् सिद्धम् ॥ छ ॥ इत्याचार्यश्रीहेमचंद्रानुस्मृते सिद्धहेमचंद्रनाम्नि शब्दानुशासनेऽष्टमस्याध्यायस्य चतुर्थः पादः समाप्तः ॥ छ ॥ अष्टमोऽध्यायः समाप्तः ॥ छ ॥ समाप्तं चेदं सिद्धहेमचंद्राभिधानशब्दानुशासनमिति ॥ छ ॥

(2) Haimaliṅganuśasana (२) हैमलिङ्गानुशासन

Folios – 97-113
Language – Sanskrit
Author – Hemacandrācārya
Size – 15 × 2 inches
Condition – Good
Age of MS. – 1293 V.S.

अन्तः—

निःशेषनामलिंगानुशासनान्यभिसमीक्ष्य संक्षेपात् ।
आचार्यहेमचंद्रः समदृभदनुशासनानि लिंगानाम् ॥ छ ॥ लिंगानि समाप्तानि ॥ छ ॥

(3) Haimadhātupāṭha (३) हैमधातुपाठ

Folios – 113-138
Language – Sanskrit
Author – Hemacandrācārya
Size – 15 × 2 inches
Condition – Good
Age of MS. – 1293 V. S.

(4) Haima Uṇādisūtrapāṭha (४) हैम उणादिसूत्रपाठ

Folios – 139-161
Size – 15 × 2 inches
Language – Sanskrit
Condition – Good
Author – Hemacandrācārya
Age of MS. – 1293 V. S.
General Remarks – The extent of all the four Mss. of this bundle together is of 2090 Granthas.

अन्तः—

अनसो वहेः क्विप् सश्च डः ॥ छ ॥ इत्याचार्यश्रीहेमचंद्रानुस्मृता उणादयः समाप्ताः ॥ छ ॥ ग्रंथाग्रं २०९० ॥ छ ॥ संवत् १२९३ वर्षे अश्विन शुदि १५ सोमे स्तंभतीर्थे श्रीनरेश्वरियोग्या श्रीहेमव्याकरणसूत्रपुस्तिका लिखापिता ॥ छ ॥

*

No 238: (1) Siddhahemaśabdānuśāsana Sūtrapāṭha–up to Pada 4 of Adhyāya VII

(१) सिद्धहेमशब्दानुशासन सूत्रपाठ—सप्तमाध्यायचतुर्थपादपर्यन्त

Folios – 85
Size – 12.2 × 1.7 inches
Language – Sanskrit
Condition – Good
Author – Hemacandrācārya
Age of MS. – c. Latter half of 13th cent. V.S

आदिः—

॥ ॐ ॥ अर्हं । सिद्धिः स्याद्वादात् । लोकात् । औदन्ताः स्वराः ।

अन्तः—

समर्थः पदविधिः । इत्याचार्यश्रीहेमचन्द्रानुस्मृतौ सिद्धहेमचन्द्रनाम्नि शब्दानुशासने सप्तमस्याध्यायस्य चतुर्थः पादः ॥ छ ॥ सप्तमोऽध्यायः समाप्तः ॥

(2) Haimadhātupāṭha

(२) हैमधातुपाठ

Folios – 86–121
Size – 12.2 × 1.7 inches
Language – Sanskrit
Condition – Good
Author – Hemacandrācārya
Age of MS. – c. Latter half of 13th cent. V.S
General Remarks – Slightly incomplete

आदिः—

ॐ भू सत्तायाम् । पां पाने । घ्रां गन्धोपादानयोः ।

अन्तः—

धृषण् प्रसहने । हिंसुण् हिंसायाम् । गर्हण् विनि........

*

No. 239 : (1) Siddhahemaśabdānuśāsana Sūtrapāṭha

(१) शिद्धहेमशब्दानुशासन–सूत्रपाठ

Folios – 83
Language – Sanskrit
Author – Hemacandrācārya
Age of MS. – 1292 V. S.
Extent – Granthas 815
Size – 13 × 2 inches
Condition – Good

अंतः—

इत्याचार्यश्रीहेमचन्द्रानुस्मृते सिद्धहेमचन्द्रनाम्नि शब्दानुशासने सप्तमस्याध्यायस्य चतुर्थः पादः समाप्तः ॥ छ ॥ सप्तमोध्यायः समाप्तः ॥ छ ॥ ग्रं. ८१५ ॥ छ ॥

(2) Haimadhātupāṭha

(२) हैमधातुपाठ

Folios – 84–113
Language – Sanskrit
Author – Hemacandrācārya
Size – 13 × 2 inches
Condition – Good
Age of MS. – 1292 V. S.

हिसुण् हिंसायाम् । गर्हण् विनिंदने । षहण् मर्षणे । परस्मै भाषा ॥ छ ॥ बहुलमेतन्निदर्शनम् ॥ छ ॥ इत्याचार्यश्रीहेमचन्द्रानुस्मृताश्शुरादयो णितो धातवः समाप्ताः ॥छ॥ संवत् १२९२ ज्येष्ठ सुदि १ लिषितम् ॥ छ ॥

*

No. 240 : Siddhahemaśabdānuśasana—the Sūtrapāṭha of Adhyāya VIII

सिद्धहेमशब्दानुशासन—अष्टमाध्यायसूत्रपाठ

Folios – 98–127
Language – Sanskrit
Author – Hemacandrācārya
Age of MS. – c. First half of 14th cent. V.S.
Size – 14.5 × 1.7 inches
Condition – Good

अन्तः—

शौरसेनीवत् । व्यत्ययश्च । शेषं संस्कृतवत् सिद्धम् ॥ छ ॥ इत्याचार्यश्रीहेमचंद्रानुस्मृते सिद्धहेमचंद्रनाम्नि शब्दानुशासनेऽष्टमस्याध्यायस्य चतुर्थः पादः । अष्टमोऽध्यायः समाप्तः ॥ छ । छ ॥ समाप्तं चेदं सिद्धहेमचंद्राभिधानशब्दानुशासनम् ॥ छ ॥ ॥ छ ॥ मंगलं महाश्रीः ॥ शुभं भवतु लेखकपाठकयोः ॥ मंगलमस्तु ॥ छ ॥

आसीद् विशांपतिरमुद्रचतुःसमुद्र-
मुद्रांकितक्षितिभरक्षमबाहुदंडः ।
श्रीमूलराज इति दुर्द्धरवैरिकुंभि-
कंठीरवः शुचिचुलुक्यकुलावतंसः ॥

*

No. 241 : Siddhahemaśabdānuśāsana with the author's own Bṛhadvṛtti– up to Sūtra 89 of Pāda 2 of Adhyāya II

सिद्धहेमशब्दानुशासन–स्वोपज्ञबृहद्वृत्तिसह–द्वितीयाध्याय द्वितीयपाद ८९ सूत्रपर्यन्त

Folios – 354
Language – Sanskrit
Author & Commentator – Hemacandrācārya
Age of MS. – c. beginning of 14th cent. V. S.
Size – 15 × 1.5 inches
Condition – Fair

*

No. 242 : Siddhahemaśabdānuśāsana with the author's own Bṛhadvṛtti– from II. 3 to III. 2

सिद्धहेमशब्दानुशासन स्वोपज्ञबृहद्वृत्तिसह : अ० २ पा० ३ – अ० ३ पा० २

Folios – 228
Language – Sanskrit
Author & Commentator – Hemacandrācārya
Age of MS. – c. Latter half of 13th cent. V. S.
Size – 9.7 × 2.2 inches
Condition – Good

आदिः—

॥ ॐ ॥ अर्हं ॥ नमस्पुरसो गतेः कखपफि रः सः ॥ गतिसंज्ञकयोर्नमस् पुरस् इत्येतयोः सम्बन्धिनो रेफस्य कखपफेषु परेषु सकारादेशो भवति ।

अन्तः —

इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनवृत्तौ तृतीयस्याध्यायस्य द्वितीयः पादः समाप्तः ॥ छ ॥ ॐ ॥

श्रीमद्दुर्लभराजस्य प्रतापः कोऽपि दुःसहः ।
प्रसरं वैरिभूपेषु दीर्घनिद्रामकल्पयत् ॥ छ ॥

*

No. 243 : Siddhahemaśabdānuśāsana with the authorś own Bṛhadvṛtti : II. 3 to III. 2 along with Annotations

सिद्धहेमशब्दानुशासन स्वोपज्ञ बृहद्वृत्तिसह : अ० २ पा० ३—अ० ३ पा० २ : टिप्पणीसह

Folios – 254
Language – Sanskrit
Author & Commentator – Hemacandrācārya
Age of MS. – c. First half of 14th cent. V. S.
General Remarks – Folios 62–63 missing.
Size – 17 × 2.2 inches
Condition – Good

*

No. 244 : Siddhahemaśabdānuśāsana with the author's own Bṛhadvṛtti : upto III. 2

सिद्धहेमशब्दानुशासन–स्वोपज्ञबृहद्वृत्तिसह : तृतीयाध्याय द्वितीयपाद पर्यन्त

Folios – 300
Size – 14.5 × 2.2 inches
Language – Sanskrit
Condition – Fair
Author & Commentator – Hemacandrācārya
Age of MS. – c. Latter half of 14th cent. V. S.

*

No. 245 : Siddhahemaśabdānuśāsana-Svopajña-Bṛhadvṛtti III. 2—IV. 4.81 : Ākhyatavṛtti

सिद्धहेमशब्दानुशासन–स्वोपज्ञबृहद्वृत्ति : तृतीयाध्याय–द्वितीयपाद्—अ० ४-४-८१ सूत्रपर्यन्त : आख्यातवृत्ति

Folios – 208
Size – 16.7 × 2.2 inches
Language – Sanskrit
Condition – Good
Author & Commentator – Hemacandrācārya
Age of MS. – c. Beginning of 14th cent. V. S.
General Remarks – Folio 1 missing.

*

No. 246 : Siddhahemaśabdānuśāsana with the author's own Bṛhadvṛtti : III. 2 toV. 4 : Ākhyatavṛtti and Kṛdvṛtti

सिद्धहेमशब्दानुशासन–स्वोपज्ञबृहद्वृत्तिसहित : तृतीयाध्याय द्वितीयपाद—पंचमाध्याय चतुर्थपाद पर्यन्त : आख्यातवृत्ति तथा कृद्वृत्ति

Folios – 253
Size – 15.2 × 2.2 inches
Language – Sanskrit
Condition – Good
Author & Commentator – Hemacandrācārya
Age of MS. – c. First half of 14th cent. V. S.
General Remarks – Folio 158 missing.

*

No. 247 : Siddhahemaśabdānuśāsana-the author's own Bṛhadvṛtti : Adhyāya V : Kṛdvṛtti

सिद्धहेमशब्दानुशासन–स्वोपज्ञबृहद्वृत्ति : पञ्चमाऽध्यायः कृद्वृत्ति

Folios – 198
Size – 15.2 × 2.2 inches
Language – Sanskrit
Condition – Good
Author – Hemacandrācārya
Age of MS. – 1300 V. S.

अन्तः—

अतादर्थ्यार्थमक्रियोपपदार्थे चेदं प्रस्तूयत इति ॥ छ ॥ इत्याचार्यश्री**हेमचंद्र**-विरचितायां **सिद्धहेमचंद्राभिधानस्वोपज्ञशब्दानुशासनवृत्तौ** पंचमस्याध्यायस्य चतुर्थः पादः। पंचमोऽध्यायः समाप्तः ॥ छ ॥

क्षुण्णाः क्षोणिभृतामनेन कटका भग्नाऽथ **धारा** ततः
कुण्ठ**स्सिद्धपतेः** कृपाण इति रे मा मंसत क्षत्रियाः ।
आरूढप्रबलप्रतापदहनः संप्राप्तधारश्चिरात्
पीत्वा **मालवयोषिदश्रु**सलिलं हंतायमेधिष्यति ॥ छ ॥

संवत् १३०० वर्षे वीजापुरपोषधशालायां समस्तश्रावकैः **कृतबृहद्वृत्तिपुस्तिका** लिखापिता सा० **रत्नपाल** श्रे० **वील्हण** ठ० **आसपाल** सा० **लाहडेन** लिखापितम् ।

*

No. 248 : Siddhahemaśabdānuśāsana with Bṛhadvṛtti : Adhyāyas VI–VII : Taddhitavṛtti

सिद्धहेमशब्दानुशासन–स्वोपज्ञबृहद्वृत्तिसह–षष्ठ-सप्तम अध्यायः तद्धितवृत्ति

Folios – 330
Size – 15 × 2.2 inches
Language – Sanskrit
Condition – Good
Author & Commentator – Hemacandrācāryā
Age of MS. – c. First half of 14th cent. V. S.

*

No. 249 : Siddhahemaśabdānuśāsana with Bṛhadvṛtti : Adhyāya VI : Taddhitavṛtti Part I

सिद्धहेमशब्दानुशासन–स्वोपज्ञबृहद्वृत्तिसह : षष्ठ अध्याय : तद्धितवृत्ति–पूर्वखंड

Folios – 197
Size – 15.2 × 2.2 inches
Language – Sanskrit
Condition – Good
Author & Commentator – Hemacandrācārya
Age of MS. – 1298 V.S.

अन्तः—

ऋत्विजमर्हति आर्त्विजीनो यजमानः। ऋत्विक्कर्म आर्त्विजीनः। ऋत्विगेव ॥ छ ॥ इत्याचार्यश्री**हेमचंद्र**विरचितायां **सिद्धहेमचंद्राभिधानस्वोपज्ञशब्दानुशासनवृत्तौ** षष्ठाध्यायस्य चतुर्थपादः समाप्तः ॥

भूमिं कामगवि स्वगोमयरसैरासिंच रत्नाकर
मुक्तास्वस्तिकमातनु त्वमुडुप त्वं पूर्णकुंभीभव ।

धृत्वा कल्पतरोर्दलानि सरलैर्दिग्वारणास्तोरणा-
न्याधत्त स्वकरैर्विजित्य जगतीं नन्वेति सिद्धाधिपः ॥ ४ ॥

संवत् १२९८ वर्षे द्वितीयभाद्रपद वदि ७ गुरौ लिखितेयम् । शुभं भवतु ।
वीजापुरे पोषधशालायां तद्धितप्रथमखंडं समस्तश्रावकैर्लिखापितम् ॥ छ ॥ तद्धितः ॥

*

No. 250 : Siddhahemaśabdānuśāsana Laghuvṛtti up to Adhyāya III, Pāda 2 : Catuṣkavṛtti

सिद्धहेमशब्दानुशासन स्वोपज्ञलघुवृत्ति तृतीयाध्याय द्वितीयपादपर्यन्त–चतुष्कवृत्ति

Folios – 212
Size – 8.2 × 1.7 inches
Language – Sanskrit
Condition – Good
Author & Commentator – Hemacandrācarya
Age of MS. – c. First half of 14th cent. V. S.
General Remarks – Folios 122, 125, 132, 142, 205, 206-209 missing.

*

No. 251 : Siddhahemaśabdānuśāsana with Laghuvṛtti : up to Adhyāya III, Pāda 2 : Catuṣkavṛtti

सिद्धहेमशब्दानुशासन स्वोपज्ञलघुवृत्तिसह–तृतीयाध्याय द्वितीयपादपर्यन्त–चतुष्कवृत्ति

Folios – 142
Size – 14.5 × 2.2 inches
Extent – Granthās 1600
Language – Sanskrit
Condition – Good
Author & Commentator – Hemacandrācaryā
Age of MS. – c. Latter half of 13th cent. V.S.

आदिः—

ॐ ॥ अर्हं ॥ प्रणम्य परमात्मानं श्रेयः शब्दानुशासनम् ।
आचार्यहेमचन्द्रेण स्मृत्वा किंचित् प्रकाश्यते ॥

अन्तः—

॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासन-लघुवृत्तौ तृतीयस्याध्यायस्य द्वितीयः पादः ॥ छ ॥ ग्रंथ १६००॥ छ ॥ शिवमस्तु ॥ छ ॥

*

No. 252 : Siddhahemaśabdānuśāsana with Laghuvṛtti : up to II. 3. 79.

सिद्धहेमशब्दानुशासन स्वोपज्ञलघुवृत्तिसह : द्वितीयाध्याय–तृतीयपाद सूत्र ७९ पर्यन्त

Folios – 90
Size – 15 × 1.7 inches
Language – Sanskrit
Condition – Good

Author & Commentator – Hemacandrācārya
Age of MS. - c. Latter half of 13th cent. V.S.

अन्तः —

प्रणिवहति । प्रणिशाम्यति । प्रणिचिनोति । प्रणियाति । प्रणिवाति ।

*

No. 253 : Siddhahemaśabdānuśasana Avacūrṇikā : Durgapadavṛtti

सिद्धहेमशब्दानुशासन अवचूर्णिका : दुर्गपदवृत्ति

Folios – 298
Size – 14 × 1.5 inches
Language – Sanskrit
Condition – Good
Age of MS. – 1264 V. S.
General Remarks – First three folios and last three folios are dilapidated in condition.

आदिः —

सर्वज्ञं सर्वदेवार्च्यं प्रणम्य विवृणोम्यहम् ।
हैमव्याकरणाद्भवृत्तिदुर्गपदावलीम् ॥ १ ॥

तत्रादौ तावदभिमतदेवतानमस्कारस्य शास्त्रसंबंधप्रयोजनयोश्च प्रतिपादनाय वृत्तिकारः श्लोकमेकमकार्षीत् । **प्रणम्य परमात्मान**मित्यादि । इह हि शिष्टाः क्वचिदिष्टे वस्तुनि प्रवर्त्तमानाः शिष्टसमयपरिपालनार्थं प्रारब्धेष्टवस्तुनिर्विघ्नपरिसमाप्त्यर्थं च इष्टदेवतानमस्कार-पुरस्कारेणैव प्रवर्त्तन्ते । अयमपि च श्रीमदाचार्य**हेमचंद्रश्चौलुक्य**चंद्रश्रीमत्**कुमारपाल**-भूपालवंदितपादारविंदः शिष्टसमयपरिपालनार्थं प्रारब्धश्री**सिद्धहेमचंद्राभिधानस्वोपज्ञ-शब्दानुशासनवृत्ति**निर्विघ्नपरिसमाप्त्यर्थं च श्लोकस्य पादद्वयेनाभिमतदेवतानमस्कारं श्रोतृ-जनप्रवृत्त्यर्थं च शास्त्रस्य संबंधप्रयोजने प्रत्यपीपदत् । तत्र प्रणम्येति प्रातेः क्वचिदिति डे । पिपर्त्तेः पृणातेर्वा खुरक्षुरेति निपातनात् । प्रशब्दः साधुः । तस्माच्च सेर्लुपि प्रत्ययाश्रितत्वेन बहिरंगोऽपि प्रकृत्याश्रितत्वेनांतरंगमपि समासं बाधित्वा प्रथममेव भवति । बहिरंगाऽपि लुप् अंतरंगान् विधीन् बाधत इति न्यायात् । ततः प्रपूर्वान्नमेः समासे सति प्राक्काले इत्यनेन क्त्वाप्रत्ययः । नन्वत्र अहन्पंचमस्य क्विक्ङिति अनेन दीर्घत्वं परत्वेन कृताकृत-प्रसागत्ववशान्नित्याद्यवादेशात् प्रागेव मा भूत् परा .... यदुच्यते । ज्ञापयत्यंतरंगाणां यया भवति बाधनम् ॥ इत्यतो दीर्घत्वात् प्रथ............................
........नमित्यत्र कर्माणि कृत इति षष्ठी प्राप्नोति । सा च तृन्नुदंतेत्यादिना निषिध्यते । श्रेय इत्यत्र प्रशस्यस्य श्र इत्यादेशविधानबलात् क्रियाशब्दत्वेन अगुणांगादपि प्रशस्य-

शब्दादीयस् नैकस्वरस्येति निषेधात् त्र्यंत्यस्वरादेरिति नांत्यस्वरादेर्लोपः। अवर्णेवर्णस्येत्यपि न। त्र्यंत्यस्वरादेरनेकस्वरस्येति एकसूत्राकरणात्। शब्दानुशासनमित्यत्र कथं कृतीति षष्ठीसमासः। तृतीयायामिति निषेधात्। सत्यम्। प्रत्यासत्तिन्यायेन यं कृतं अपेक्ष्य षष्ठी तमेव कृतमपेक्ष्य यदि तृतीया स्यात्तदा आचार्यहेमचंद्रेणेति तृतीयासद्भावात् आश्चर्यो गवां दोहोऽगोपालकेनेतिवत् षष्ठीसमासनिषेधः स्यात्। अत्र तु प्रकाश्यत इत्यपेक्षया तृतीया। अनुशासन इत्यपेक्षया तु षष्ठीति न समासनिषेधः। आचर्यते सेव्यते विनयार्थं विद्याग्रहणार्थं वा शिष्यैरिति ध्यण् १। आचारे साधुरिति तत्र साधौ यः २। आचारान् यातीति क्वचित् डः ३। आचारानाचष्ट इति णिज् बहुलं नास्तीति णिजि आचारयतीति शिक्यस्योद्येति सो निपात्यते ४। आचारान् गृह्णाति ग्राहयति वा पृषोदरादित्वात् साधुः ५। किमपि चिनोतीति क्विप् १। किमः सर्वविभक्त्यंतात् चिच्चनाविति वा २। किंचिदित्यखंडमव्ययं वा ३। अत्र सर्वपार्षदत्वात् व्याकरणस्य परमात्मानमित्यनेनानिर्दिष्टनाम्ना सामान्येन देवताया निर्देशः कृतः। सर्वैरपि हि स्वकीयः २ देवता परमात्मेत्युच्यते। नमस्कार्यश्च स एव भवति यस्य पूजातिशयवचनातिशय-ज्ञानातिशयाऽपायापगमातिशयलक्षणमतिशयचतुष्टयं भवति। तत्र परमात्मानमित्यनेन पूजातिशयः प्रकाशितः। अत एव सन्महत्परमेत्यनेन पूजायां समासः।

अन्तः—

कडारा। जैमनि कडार इति। जेमंतीति विच् जेमामिनः जेमिनः यद्वा जिमेर्विपिना-जिनादय इतीने जिमिनस्तस्यापत्यं ऋषित्वेऽपि बाह्वादेराकृतिगणत्वादिञ्। जैमिनिः। गड्डुलगालव इति। गड्डुरस्यास्ति सिध्मादि० लगडोरपत्यं ऋष्यण्० ऋफिडादित्वाल्लः ॥ छ ॥ धर्मार्थौ विपूयविनीयजित्या इति। यादृश एव गणे दृष्टस्तादृश एव प्रयोगः न तु विनीयविपूयजित्यादयः। जित्याशब्दस्यैव पूर्वपरभावः ॥ छ ॥ लघ्वक्षरा। अक्षरशब्देन स्वरोऽभिधीयते। शरशीर्षमिति पाठः। शरशीर्षमिति तु पाठे प्राणित्तयेति स्वैरभावात् समाहाराप्राप्तिः। श्रद्धामेधे इति। अर्थग्राहिणी श्रद्धा शब्दग्राहिणी मेधा श्रद्धामूलत्वादभि-प्रेतार्थसिद्धेरर्च्यत्वं। दीक्षा तपसीत्यादिषु दीक्षाश्रद्धामेधानां बहूपकारकैत्वान्मूलभूतत्वाच्चार्चित-त्वात् परत्वात् पूर्वनिपातः। मातापितराविति। अनुभूतगर्भादिक्लेशत्वात् पितृतो माताऽभ्यर्हिता। एवं स्त्रीप्रधानत्वाद्विवाहस्य वराद्वधूरिति। एकस्यैव यथाप्राप्तमिति। दुंदुभिशब्दादिदंतात् परत्वादल्पस्वरत्वात् शंखवीणाशब्दयोर्युगपत् पूर्वनिपातप्राप्तावेकग्रहणादेकस्यैव क्रमेण पूर्वनिपातः। शेषाणां त्विति। शंखवीणाशब्दयोः अश्वइंद्रशब्दयोरेव युगपत् पूर्वनिपातप्राप्तौ

एकस्यैव पूर्वनिपातः। दुंदुभिरथादीनां तु कामचार इत्यर्थः। एकस्यैवेत्युक्तेऽपि दुंदुभि-रथादीनां न पूर्वनिपातः शब्दस्य स्पर्द्धे परत्वात्तथाहि दुंदुभिशब्दोऽसखीदुत् शंखवीणाशब्दौ तु अल्पस्वराविति। एवमश्वरथेंद्रा इत्यत्रापि रथशब्दो लघ्वक्षरः। अश्वेंद्रशब्दौ च परौ इति तयोरेव पूर्वनिपातो न तु रथस्य। शंखदुंदुभिवीणा इति। प्राण गणो वः मांगल्यवाचकत्वेन शंखशब्दस्य विवक्षितत्वात् स्वैरित्वभावाद्वा। यतः तूर्यांगस्य तूर्यांगे न हि स्वयं भवति इति। एवं मृदंगशंखपणवा इति। अथवा शंखदुंदुभिवीणामृदंगशंखपणवा इति शंखादीनां तूर्यांगत्वादेकवद्भावः कुतो न भवतीति। उच्यते। अत्र शंखादिशब्देन शंखादिसमुदायस्याभिधानात्तस्य चातूर्यांगत्वादजातित्वाच्च नैकवद्भावः। उत्पलस्त्वाह। तूर्यांगताशंखादिवादकानां न तु शंखादीनामिति तूर्यांगत्वादत्रैकवद्भावो नाशंकनीयः। अत एव प्राणितूर्यांगाणामित्यत्र पूर्वैर्मार्दंगिकपाणविकवीणावादकपरिवादकमित्येवोदाहियते न तु भेरीमृदंगमित्यादि। तदा तु प्राणिरूपं तूर्यांगं प्राणितूर्यांगमिति विग्रहः ॥ छ ॥ मासव। ब्राह्मणक्षत्रियाविति। अत्रानियमः प्राप्तः। क्षत्रियवैश्यावित्यत्र त्वल्पस्वरत्वाद्वैश्यशब्दस्य पूर्वनिपातः प्राप्तो वैश्य-शूद्रावित्यत्राप्यनियमः। ब्राह्मणक्षत्रियविट्शूद्रा इत्यत्र त्वल्पस्वरत्वाद्विशः पूर्वनिपाते प्राप्तेऽनेन ब्राह्मणादीनामनुपूर्वं पूर्वनिपातः। आनुपूर्व्यं च जन्मकृतम्। यदाह। मुखतो ब्राह्मणा जाता बाहुभ्यां क्षत्रियाः स्मृताः। ऊरुभ्यां तु विशः प्रोक्ताः पद्भ्यां शूद्रो अजायत ॥ न चात्रार्च्यत्वात् पूर्वनिपातः सिध्यतीति वाच्यम्। निंदितस्यापि ब्राह्मणादेः संभवादिति ॥ छ ॥ भर्तृतुल्य। अत्रापि नक्षत्राणामृतूनां चानुपूर्व्यं लोकप्रसिद्धचैव वेदितव्यम्। छ ॥ संख्यास। द्विदशा इति। ननु द्विदशा इत्यादौ सुज्वार्थे इत्यनेन सुजर्थे समासः। ततः प्रथमोक्तं प्रागित्यनेनापि सिध्यति। किमेषामुपादानम्। सत्यं यदा दशन्शब्दः सुजर्थः समस्यते तदाप्यनेनानुपूर्व्या संख्यायाः पूर्वनिपातो भवतीति फलम् ॥ छ ॥ इत्याचार्य-श्री**हेमचंद्रा**नुस्मृते **सिद्धहेमचंद्रनाम्नि शब्दानुशासने** अवचूर्णिकाया तृतीयस्याध्यायस्य प्रथमः पादः संपूर्णः ॥ छ ॥ संवत् १२६४ वर्षे श्रावण शुदि ३ रवौ श्री**जयानंदसूरि** शिष्य **अमरचंद्रेण आ[त्मकृते] अवचूर्णिकायाः प्रथमपुस्तिका लिखिता** ॥ शुभं भवतु लेखकपाठकयोः ॥ छ ॥

*

No. 254 : Siddhahemaśabdānuśāsana with Bṛhadvṛtti : Adhyāya VIII : Prākṛtādivyākaraṇa

सिद्धहेमशब्दानुशासन स्वोपज्ञबृहद्वृत्तिसह : अष्टमाध्याय-प्राकृतादिव्याकरण

Folios – 223 Size – 14.7 × 1.7 inches

Language – Sanskrit
Author & Commentator – Hemacandrācārya
Condition – Good
Age of MS. – 1224 V. S.

आदिः—

॥ ॐ नमो वीतरागाय ॥

अथ प्राकृतं । अथ शब्दआनंतर्यार्थोऽधिकारार्थश्च प्रकृतिः संस्कृतम् । तत्र भवं तत आगतं वा प्राकृतं संस्कृतानंतरं प्राकृतमधिक्रियते । संस्कृतानंतरं च प्राकृतस्याऽनुशासनम् । सिद्धसाध्यमानभेदसंस्कृतयोनेरेव तस्य लक्षणम् । न देश्यस्येति ज्ञापनार्थं संस्कृतसमं तु संस्कृतलक्षणेनैव गतार्थम् । प्राकृते च प्रकृतिप्रत्ययलिंगकारकसमाससंज्ञादयः संस्कृतवद्वेदितव्याः । लोकादिति च वर्त्तते । तेन ऋॠऌॡऐऔङञशष विसर्जनीयप्लुतवर्जो वर्णसमाम्नायो लोकादवगंतव्यः । ङञौ स्ववर्ग्यसंयुक्तौ भवत एव । ऐदौतौ च केषांचित् । कैतवं कैअवं सौदर्यं सौअरियं । कौरवाः कौरवा । तथाऽस्वरं व्यंजनं द्विवचनं चतुर्थीबहुवचनं च न भवति ॥ छ ॥

अन्तः—

शेषं संस्कृतवत् सिद्धम् । शेषं यदत्र प्राकृतादिभाषास्वष्टमे नोक्तं तत्सप्ताध्यायीनिबद्धसंस्कृतवदेव सिद्धम् । हेट्ठट्ठिअसूरनिवारणाय । अत्र चतुर्थ्या आदेशो नोक्तः । स च संस्कृतवदेव सिद्धः । उक्तमपि क्वचित् संस्कृतवदेव भवति । यथा प्राकृते उरस् शब्दस्य सप्तम्येकवचनान्तस्य उरे उरम्मि इति प्रयोगौ भवतः तथा क्वचिदुरसीत्यपि भवति । एवं सिरे सिरम्मि सिरसि सरे सरम्मि सरसि । सिद्धग्रहणं मंगलार्थम् । ततो ह्यायुष्मच्छ्रोतृकताभ्युदयश्चेति ॥ छ ॥ इत्याचार्यश्रीहेमचंद्रविरचितायां **सिद्धहेमचंद्राभिधानस्वोपज्ञशब्दानुशासनवृत्तौ** अष्टमस्याऽध्यायस्य चतुर्थः पादः समाप्तः ॥ **अष्टमोध्यायः समाप्तः** ॥ छ ॥ समाप्ता चेयं **सिद्धहेमचंद्रशब्दानुशासनवृत्तिः प्रकाशिकानामेति समाप्तमिति** ॥ छ ॥

आसीद्विशांपतिरमुद्रचतुस्समुद्रमुद्रांकितक्षितिभरक्षमबाहुदंडः ।
श्री**मूलराज** इति दुर्द्धरवैरिकुंभिकंठीरवः शुचिचुलक्यकुलावतंसः ॥ ३२ ॥

तस्याऽन्वये समजनि प्रबलप्रतापस्तिग्मद्युतिः क्षितिपति**र्जयसिंहदेवः** ।
येन स्ववंशसवितर्य्यपरं सुधांशौ **श्रीसिद्धराज** इति नाम निजं व्यलेखि ॥३३॥

सम्यग् निषेव्य चतुरश्चतुरोऽप्युपायान् जित्वोपभुज्य च भुवं चतुरब्धिकांचिम् ।
विद्याचतुष्टयविनीतमतिर्जितात्मा काष्ठामवाप पुरुषार्थचतुष्टये यः ॥ ३४ ॥

तेनाऽतिविस्तृतदुरागमविप्रकीर्णशब्दानुशासनसमूहकदर्थितेन ।
अभ्यर्थितो निरवमं विधिवद् व्यधत्त शब्दानुशासनमिदं मुनिहेमचंद्रः ॥ छ॥

संवत् १२२४ वर्षे भाद्रपद शुदि ३ बुधे महं० चंडप्रसादेन सुत यशोधवलस्यार्थे लेखिता ॥

*

No. 255: Haimaliṅgānuśāsana with Vivarṇa

हैमलिङ्गानुशासन–स्वोपज्ञविवरणसह

Folios – 222
Size – 12.2 × 2 inches
Language – Sanskrit
Condition – Good
Author & Commentator – Hemacandrācārya
Age of MS. – c. Latter half of 13th cent. V. S.
General Remarks – Somewhat incomplete.

आदिः—

॥ ॐ नमो जिनाय ॥ अर्हम् ॥

श्रीसिद्धहेमचंद्रव्याकरणनिवेशितानि लिंगानि ।
आचार्यहेमचंद्रो विवृणोत्यर्हं नमस्कृत्य ॥

लिंगानुशासनमंतरेण शब्दानुशासनं नाविकलमिति सामान्यविशेषलक्षणाभ्यां लिंगमनुशिष्यते । पुलिंगं कटणथपभमयरषसस्नु ।

*

No. 256: (1) Kātantra (?) Pañjikopayogī Parasūtrakadambaka (?)

(१) कातन्त्रपञ्जिकोपयोगी परसूत्रकदम्बक (?)

Folios – 52
Size – 14.5 × 1.2 inches
Language – Sanskrit
Condition – Good
Age of MS. – 1287 V.S.
General Remarks – Folio 52 contains picture-decoration.

आदिः—

उपकारीदमत्यंतं पंजिकायामतो बुधैः ।
शास्त्रांतरात् समादत्तं परसूत्रकदंबकम् ॥ १ ॥

ह्रस्वं लघु । संयोगे गुरु । दीर्घं च । वर्गो वर्गेण सवर्णः । मनोरनूष्मण्यनुस्वारः । सुप्तिङंतं पदं । चादयोऽसत्त्वे निपाताः । स्वरादिनिपातमव्ययम् । प्रादयः क्रियायोगे

उपसर्गास्ते च प्राग्धातोः । अपादानादिकारकं । तुड्यादिलक्षणः कालः । एकादिव्यवहारहेतुः संख्या । अदर्शनं लोपः । प्राग्दीव्यतोऽण् ।' तदस्मिन्नस्तीति देशे तन्नाम्नि । तेन निर्वृत्तः। तस्य निवासः । अदूरभवश्चावरणादिभ्यश्च जनपदे लुक् । लुपि युक्तवद्व्यक्तिवचने । तदशिष्यं संज्ञाप्रमाणत्वात् । लुप्योगाप्रख्यानात् । प्लक्षादिभ्योऽण् । हरीतक्यादिभ्यश्च एकादाकिनिच्चासहाये । मृदस्तिकन् । सस्नौ प्रशंसायां । वने लुक् ॥ छ ॥ **इति प्रथमः संधिः** ॥ छ ॥

अन्तः—

नां चेः प्रकाशने । पूजायां मिट् न लोपो न सिनोतेः कर्मकर्त्तरिग्रासे । त्राधातोर्वा । न संज्ञायां त्रायतेर्नित्यं । संफुल्लोत्फुल्लपरिक्लशाः ॥ छ ॥ **कृत्परसूत्राणि समाप्तानि** ॥ छ ॥

(2) Kātantra(?)pañjikopayogī Uṇādiparasūtra-kadambaka (?)

(२) कातन्त्र(?)पञ्जिकोपयोगी उणादिपरसूत्रकदम्बक (?)

Folios – 53-62
Language – Sanskrit
Age of MS. – 1287 V. S.
Size – 14.5 × 1.2 inches
Condition – Good

आदि :—

आद्यरयोखनिस्वभ्यां द्रुः । मद्यं किवासिमथिवतिभ्य उरः । मकुरदर्दुरविधुराः । शावसेराप्तौ । अविमत्सौ पूयः । रुहेर्वृद्धिश्च । किल्बियाव्यथियौ । तिमिरुचिमदिवंमंदिवंदिविधेरुचिशुचिभ्यः किरः । अजिरादयः ।

अन्त :—

सिचेः संज्ञायां । व्याजिघ्रश्च जातौ । हंतेर्घुरगृहेरणि । प्रथेरमचमंगेरलच् । **इत्युणादौ षष्ठः पादः समाप्तः** ॥ छ ॥ **उणादिः समाप्ता इति** ॥ छ ॥

(3) Vāmanīya Liṅgānuśāsana (३) वामनीय लिङ्गानुशासन

Folios – 63-66
Language – Sanskrit
Author – Vāmanācārya
Age of MS. – 1287 V. S.
Extent – Granthas 25
Size – 14.5 × 1.2 inches
Condition – Good

आदिः—

सिद्धं विबुधजनेष्टं विदिताऽखिलवाङ्मयं प्रणम्याप्तम् ।
लिंगानुशासनमहं वच्म्यार्याभिः समासेन ॥ १ ॥

नाम नपुंसकलिंगं तत्तनलस्तुत्वशब्दपर्यंतम् ।
मन्नंतो द्विजदितमपि संतं हल्यूर्व्वररुजातम् ॥ २ ॥

अंतः—

अद्यापि संशयगतार्थमनिष्टसंगलिंगानुशासनमिहाज्ञतया मया यत् ।
प्रोक्तं हि किंचिदविचार्य तदार्यवर्यैः संस्कार्यमस्ति यदि कार्यमुतावधीर्यम् ॥ १० ॥
लिंगानुशासनमिदं कृतमुन्नतेन शुभ्रैर्गुणैः कविहितं भुवि **वामनेन** ।
बुध्वाऽखिलं विमलशब्दगतप्रमेयं नातः परं स्फुटतरं शुभमस्ति लोकाः ॥ ११ ॥

इति श्री**वामनाचार्य**कृतं **लिंगानुशासनं** समाप्तमिति ॥ छ ॥ * ॥ छ ॥ संवत् १२८७ वर्षे वैशाख सुदि गुरावद्येह **वीजापुरीयश्रावकपोषधशाला**यां पूज्यश्री**देवेंद्रसूरि विजयचंद्रसूरि** उपाध्यायश्री**देवभद्रगणेः** सद्गुरूणां धर्मोपदेशतः सा० **रत्नपाल** सा० **लाहड** श्रे० **वील्हण** ठ० **आसपाल** परसूत्रपुस्तिका लिखापिता ।

*

No. 257 : Siddhahemaśabdānuśāsana–Uṇādigaṇa with Svopajña Vivaraṇa
सिद्धहेमशब्दानुशासन–उणादिगण–स्वोपज्ञविवरणसहित

Folios – 197 Size – 17.5 × 2 inches
Language – Sanskrit Condition – Good
Author & Commentator – Hemacandrācārya
Age of MS. – c. First half of 15th cent. V.S.
General Remarks – The ms. is corrected in 1460 V.S.

आदिः—

॥ अर्हम् ॥

श्री**सिद्धहेमचंद्रव्याकरण**निवेशिनामुणादीनाम् ।
आचार्य**हेमचंद्रः** करोति विवृतिं प्रणम्यार्हम् ॥ छ ॥

कृवापाजिस्वादिसाध्यशौदृस्नासनिजनिरहीण्भ्य उण् । करोत्यादिभ्यो धातुभ्यः सत्यर्थे वर्त्तमानेभ्यः संप्रदानापादानाभ्यामन्यत्र कारके भावे च संज्ञायां विषये बहुलमुण्-प्रत्ययो भवति ।

अन्तः—

अनसो वहेः क्विप्सश्च डः । अनसशब्दपूर्वात् वहीं प्रापणे इत्यस्मात् क्विप्प्रत्ययो सकारस्य च डो भवति । अनो वहति । अनड्वान् वृषभः ॥ छ ॥ इत्याचार्यश्री**हेम-**

चंद्रानुकृतं स्वोपज्ञोणादिगणसूत्रविवरणं समाप्तम् ॥ छ ॥ मंगलं महाश्रीः ॥ शुभं भवतु ॥ छ ॥ संवत् १४६० वर्षे चैत्र वदि ९ गुरावशोधि शुद्धपुस्तिकयेयं पुस्तिका । भद्रम् ॥

*

No. 258 : Abhidhānacintamaṇināmamālā

अभिधानचिन्तामणिनाममाला

Folios – 190
Language – Sanskrit
Author – Hemacandrācārya

Size – 12.5 × 1.7 inches
Condition – Good
Age of MS. – c. Latter half of 13th cent. V. S.

आदिः—

॥ अर्हम् ॥

प्रणिपत्यार्हतः सिद्धसांगशब्दानुशासनः ।
रूढयौगिकमिश्राणां नाम्नां मालां तनोम्यहम् ॥ १ ॥

अन्तः—

ननु च स्याद्विरोधोक्तौ पक्षांतरे तु चेद्यदि ।
शनैर्मंदे वरे त्वर्वाक् रोषोक्तावुन्नतौ नमः ॥ १७८ ॥

इत्याचार्यश्रीहेमचंद्रविरचितायामभिधानचिंतामणौ नाममालायां सामान्य-काण्डः षष्ठः समाप्तः ॥

*

No. 259 : Abhidhānacintamaṇināmamālā with Vṛtti

अभिधानचिन्तामणिनाममाला—स्वोपज्ञवृत्तियुता

Folios – 250
Language – Sanskrit
Author & Commentator – Hemacandrācārya
Age of MS. – 1376 V. S.

Extent – Granthas 10000
Size – 37.7 × 2.5 inches
Condition – Good

आदिः—

॥ अर्हम् ॥

धर्मतीर्थकृतां वाचं नत्वा तत्त्वाभिधायिनीम् ।
स्वोपज्ञनाममालाया विवृतिं विदधाम्यहम् ॥ १ ॥
श्रेयोर्थमयमारंभः किं तत्रात्मविकत्थनैः ।
परात्मनिन्दास्तोत्रे हि नाद्रियन्ते मनीषिणः ॥ २ ॥

प्रामाण्यं वासुकेर्व्याडेर्व्युत्पत्तिर्धनपालतः ।
प्रपञ्चश्च वाचस्पतिप्रभृतेरिह लक्ष्यताम् ॥ ३ ॥

तत्रायमादिश्लोकः—

प्रणिपत्यार्हतः सिद्धसाङ्गशब्दानुशासनः ।
रूढयौगिकमिश्राणां नाम्नां मालां तनोम्यहम् ॥

अन्तः—

इत्याचार्यश्रीहेमचन्द्रविरचितायां **स्वोपज्ञाभिधानचिन्तामणिनाममालाटीकायां** सामान्यकाण्डः षष्ठः ॥ छ ॥ ग्रन्थाग्रं श्लोक ११२० । एतस्यामभिधानचिन्तामणौ नाममालाया विवरणे षट्सु काण्डेषु ग्रन्थाग्रं १०००० ॥ समाप्ता चेयम**भिधानचिन्तामणि-नाममालाटीका** ॥ छ ॥ शुभं भवतु श्रीश्रमणसंघस्य । शान्तिर्भवतु लेखकपाठकयोः ॥

याद‍ृशं पुस्तके द‍ृष्टं ताद‍ृशं लिखितं मया ।
यदि शुद्धमशुद्धं वा मम दोषो न दीयते ॥ छ ॥

संवत् १३७६ वर्षे भाद्रवा [....] दि १ सोमदिने लिखितं लेखकेन ॥ छ ॥ छ ॥ छ ॥ छ ॥

*

No. 260 : Abhidhānacintāmaṇināmamālā with Commentary

अभिधानचिन्तामणिनाममाला—स्वोपज्ञटीकासह

Folios – 324 स्ता थ पक | Size – 32.5 × 2.5 inches
Language – Sanskrit | Condition – Good
Author & Commentator – Hemacandrācārya
Age of MS. – c. Latter half of 15th cent. V.S.
General Remarks – The reverse of the last folio having been rubbed off the closing portion has been effaced.

*

No. 261 : Kaviśikṣā कविशिक्षा

Folios – 13 | Size – 14 × 2 inches
Language – Sanskrit | Condition – Good
Author – Jayamaṅgalācārya | Age of MS. – c. 14th cent. V.S.

आदिः—

॥ ॐ नमो विघ्नराजाय ॥

प्रबोधमानंदपरंपराणां हेतुं समुल्लासिततत्त्वसेतुम् ।
युष्माकमत्युज्ज्वलमानसांतर्ब्राह्मी सुधासुंदरमातनोतु ॥ १ ॥
नानार्थकविशिक्षाणां संग्रहादसमादिह ।
मया प्रकाश्यते तत्त्वं श्रीमत्पार्श्वप्रसादतः ॥ २ ॥
औचित्यं श्लाघ्यते तत्र कविना जीवितोपमम् ।
कवयस्तदजानंतः कथं स्युः कीर्त्तिभाजनम् । ३ ॥

अन्तः—

अनुल्लसंत्यां नव्यार्थयुक्तावपि नवत्वतः ।
अर्थसंकलनातत्त्वमभ्यसेत् संकथास्वपि ॥ ६ ॥

इति श्रीजयमंगलाचार्यविरचितकविशिक्षेयं समाप्ता ।

शिवमस्तु सर्वजगतः परहितनिरता भवंतु भूतगणाः ।
दोषाः प्रयांतु नाशं सर्वत्र सुखी भवतु लोकः ॥ १ ॥

*

No. 262 : Raghuvaṃśamahākāvya—Upto Sarg XIV Śloka 168
रघुवंशमहाकाव्य—सर्ग १४ श्लो. १६८ पर्यन्त

Folios – 258	Size – 12 × 2 inches
Language – Sanskrit	Condition – Good
Author – Mahākavi Kālidāsa	Age of MS. – c. end of 13th cent. V.S.

आदिः—

॥ ॐ नमो नेमिनाथाय ॥

वागर्थाविव संपृक्तौ................

*

No. 263 : Gauḍavaho Mahākāvya **गउडवहो महाकाव्य**

Folios – 232	Size – 12.2 × 1.7 inches
Language – Prakrit	Condition – Good
Author – Vākpatirāja	Age of MS. – 1289 V. S.

आदिः—

॥ नमो कामराजाय ॥

पढमं चिय धवलकओववीअमंबुरुहगोअरं नमह ।
हरिजढरनि— —सुखित्तनालसुत्तं पिव सयंभुं ॥ १ ॥
तं पणमह तिंगिच्छिच्छलेण निवसइ निवेसकमलम्मि ।
जस्स परमाणुनिवहो व्व भुवणनिम्माणपडिवन्नो ॥ २ ॥

अन्तः—

जस्स विजयाहिसेए विवक्खदेवीहिं कयणिओयाहिं ।
पीयाइं तक्खणुप्पियचमरंतरिआइं अंसूइं ॥ ४४ ॥
तस्स इमं पावणमहिणवं विचित्तं च विम्हयकरं च ।
सीसइ चरियमचरमं णराहिवइणो णिसामेह ॥ ४५ ॥

कइरायलंछणस्स **वप्पइरायस्स गउडवहेण** गाहावीढं सम्मत्तं ॥ इति महाकाव्यं समाप्तमिति ॥ कथानिका चात्र दिव्या ॥ छ ॥ मंगलं महाश्रीः ॥ संवत् १२८९ वर्षे पौष सुदि ८ भौमे अद्येह **वटपद्रके गौडवहमहा**..............

*

No. 264: (1) Sūktāvalī (१) सूक्तावली

Folios – 13
Language – Sanskrit
Age of MS. – c. First half of 15th cent. V.S.
Extent – Kāvyas 147
Size – 13 × 1.7 inches
Condition – Good

धर्माधिकार आदिः—

॥ ॐ नमो वीतरागाय ॥

मानुष्यार्यक्षेत्रदेशान्वयायुर्नीरोगं वाऽऽचार्यबुद्ध्यादिसंपत् ।
संसारेऽस्मिन् मानवानां दुरापा सामग्रीयं धर्ममार्गे समग्रा ॥ १ ॥
इह हि भूतलवह्निनभस्वतामसुमतो बत कायममुंचतः ।
व्रजति काल उपार्जितकर्मणां स्थितिवशादपसंख्यमसौख्यतः ॥ २ ॥
अथ कथमपि प्रैति प्राणी वनस्पतिकायके-
ष्वतिगुरुतराज्ञानच्छन्नस्त्वनंततनुत्वगः ।
गमयति ततोऽनंतं कालं मलीमसकर्मणां
किमिव हि न वा योगो दद्यादशर्म शरीरिणाम् ॥ ३ ॥
द्वित्रिचतुःपरिणामपरीतैः स्यात्करणैर्यदि जंतुरुपेतः ।
कर्मबलाद् विकलेंद्रियनामा सो पि मनोविकलो न खलु ज्ञः ॥ ४ ॥

यत्राऽऽर्यलोका निवसंति देशे स्वदेशधर्मान्वयमार्गशीलाः ।
नृपाश्च सन्न्यायजनानुकूलास्तत्रोचितः श्राद्धजनस्य वासः ॥ ७२ ॥

अन्तः पत्र ९ —

पंचकल्याणकादीनामंगीकृत्य दिनादि सा ।
अन्यद्वा शासनोन्नामहेतुभूतं विधीयते ॥ १०४ ॥ छ ॥

कामाधिकार आदिः पत्र १० —

यथा धीरं धीरं रससि रससिक्तेन मरुता
रुतासक्तं केकिव्रजमपि यथाऽऽशु प्रथयसि ।
तथा शंके धाराधर धरणिमुद्धर्तुमभवद्
भवत्प्रारंभोऽयं भृशमकुशलोकम्पृणगुणः ॥ १ ॥

अंतः पत्र १३ —

कांतिस्तनोति तुलनामलिनस्तवेयं धूमाच्च भूतिरपरश्च गुणो न कश्चित् ।
किं तत्तपः कथय कज्जल येन कांतानेत्रोत्पलैरविचलैः परिपीयसे त्वम् ॥ ३८ ॥ छ ॥
[कामाधिकारः]

(2) Bodhapradīpa (२) बोधप्रदीप

Folios – 14–19
Language – Sanskrit
Age of MS. – c. First half of 15th cent. V. S.
Extent – Kāvyas 51
Size – 13 × 1.7 inches
Condition – Good

आदि :—

चूडोत्तंससितचारुचंद्रकलिकाचंचच्छिखाभासुरो
लीलादग्धविलोलकामशलभः श्रेयो दशाग्रे स्फुरन् ।
अंतःस्फूर्जदपारमोहतिमिरप्राग्भारमुच्छेदयं-
श्चेतःसद्मनि योगिनां विजयते बोधप्रदीपो हरः ॥ १ ॥

अन्त :—

किं करिष्यत्यहो तेषां मायारात्रिस्तमस्विनी ।
येषां बोधप्रदीपेन मुक्तिमार्गः प्रदर्शितः ॥ ५१ ॥ छ ॥

बोधप्रदीपोऽयम् ॥ छ ॥

(3) Subhāṣitaratnakośa (३) सुभाषितरत्नकोश

Folios – 20–39/1 Extent – Kāvyas 194
Language – Sanskrit Size – 13 × 1.7 inches
Author – Mummuṇideva Condition – Good
Age of MS. – c. First half of 15th cent. V.S.

आदिः—

॥ ॐ ॥

क्षिप्तो हस्तावलग्नः प्रसभमभिहतो व्याददानोंशुकांतं
गृह्णन् केशेष्वपास्तश्चरणनिपतितो नेक्षितः संभ्रमेण ।
आलिंगन् योऽवधूतस्त्रिपुरयुवतिभिः सास्रनेत्रोत्पलाभिः
कामीवार्द्रापराधः स दहतु दुरितं शांभवो वः शराग्निः ॥ १ ॥

पत्र २४ —

आः कष्टं किल तावदेतदपि यद्दौस्थ्यं जने श्रूयते
तत्रापि स्वगृहागतं निजदृशोर्द्वंद्वेन यद् दृश्यते ।
अन्यत्तत्पुनरत्र दुःसहतरं यद्दैन्यमालंब्यते
तस्मात् किं न कठोर हा हृदय ! रे द्वेधा त्वया भिद्यते ? ॥ ५९ ॥
व्रजत व्रजत प्राणा अर्थिनि व्यर्थतां गते ।
पश्चादपि हि गंतव्यं क्व सार्थः पुनरीदृशः ॥ ६० ॥

इति परमशैवभट्टारकमहापंडिताचार्यराजगुरुश्रीमन्मुम्मुणिदेवविरचिते सरस्वतीसर्वस्वकोशाभिधाने सुभाषितरत्नकोशे धर्माधिकारकः प्रथमबोधकः ॥ छ ॥ अथार्थाधिकारे सामान्यसमासोक्तिः ॥

पत्र २५ —

माधुर्यादतिशैत्यतः शुचितया संतापशांत्या तृषः
स्थाने मैत्रमिदं पयः पय इति क्षीरस्य नीरस्य च ।
तेऽत्राप्यर्णसि वर्णना स्फुरति मे यत्संगतौ वर्द्धते
दुग्धं येन शुचेव चास्य सुहृदः काब्धेः स्वयं क्षीयते ॥ १ ॥ कस्यापि ॥
को हि तुलामधिरोहति शुचिना दुग्धेन सहजमधुरेण ।
तप्तं विकृतिं क्षुब्धं केवलमुद्गिरति यत्स्नेहम् ॥ २ ॥

वामन फलमत्युच्चं तरुतो मरुतोपनीतमासाद्य ।
युक्तं तद्यत् तृप्यसि दृप्यसि चेत्तत्र हास्यकरम् ॥ ३ ॥

निरानंदः कौंदे मधुनि विधुरो बालबकुले
न शाले सालंबो लवमपि लवंगे न रमते ।
प्रियंगौ नासंगं रचयति न चूते विचरति
स्मरन् लक्ष्मीलीलाकमलमधुपानं मधुकरः ॥ ४ ॥

सुवर्णकार श्रवणोचितानि वस्तूनि विक्रेतुमिहागतस्त्वम् ।
कुतोऽपि नाश्रावि यदत्र पल्ल्यां पल्लीपतिर्यावदविद्धकर्ण्णः ॥ ६ ॥ कयोरपि ॥

इति **सामान्यसमासोक्तिपद्धतिः** ॥

अन्तः पत्र ३९ :—

ग्रीष्मे तुल्यगुडां सुसैंधवयुतां मेघावनद्धांबरे
तुल्यां शर्करया शरद्यभिनवे शुंठ्या तुषारागमे ।
पिप्पल्या शिशिरे वसंतसमये क्षौद्रेण तां संयुतां
राजन् प्राप्य हरीतकीमिव गदा नश्यंतु ते शत्रवः ॥ १३४ ॥

मुम्मणरचितसुभाषितावली समाप्ता ॥ छ ॥

(4) Sūktasaṅgraha (४) सूक्तसङ्ग्रह

Folios – 39/2–58
Language – Sanskrit
Age of MS. – c. First half of 15th cent. V.S.
Extent – Kāvyas 268
Size – 13 × 1.7 inches
Condition – Good
General Remarks – Incomplete.

आदिः—

तानींद्रियाण्यविकलानि तदेव नाम सा बुद्धिरप्रतिहता बचनं तदेव ।
अर्थोष्मणा विरहितः पुरुषः स एव चान्यः क्षणेन भवतीत्यतिचित्रमेतत् ॥१॥

यत्सेवंते नरपतिमहो मानवाः मानशौण्डाः
यत्संग्रामे गृह इव निजे निर्विशंका विशंति ।
यद्भाषंते परुषवचसां स्वामिनां दीनमग्रे
हेतुस्तस्मिंस्तरलनयना कामिनी काममेका ॥ २ ॥

किमिह कपालकमंडलुवल्कलसितरक्तपटजटापटलैः ।
व्रतमिदमुज्ज्वलमनसां पुंसां प्रतिपत्तिनिर्वहणम् ॥ ३ ॥

यद्गायंति च वादयंति च नृणां नृत्यंति चाग्रे सदा
नीचानामपि चित्रचाटुरचनास्तोत्राणि कुर्वंति वा ।
आरोहंति च रोहणाद्रिशिखरं क्रामंति चांभोनिधिं
मर्त्यास्तत्र निमित्तमुत्तमतमं मत्तेभकुंभस्तनी ॥ ४ ॥

*

No. 265 : (1) Sūktiratnakośa—Sūktasaṅgraha
(१) सूक्तिरत्नकोश—सूक्तसङ्ग्रह

Folios – 1-37
Language – Sanskrit
Author – Lakṣmaṇa
Extent – Granthas 613
Size – 13 × 1.7 inches
Condition – Good
Age of MS. – c. First half of 15th cent. V. S.

आदिः—

॥ ॐ नमः सर्वज्ञाय ॥

सूक्तिरत्नसुधासिंधुं ध्यात्वा श्रीश्रुतदेवताम् ।
सूक्तानां संग्रहं चक्रे **लक्ष्मणो** लक्षसूक्तिकः ॥ १ ॥

अथ जिनस्तुतिः—

चित्रं यत्रापरागेऽपि केवलज्ञानभास्करः ।
अजस्रमुदयं धत्ते जिनेंद्रः सोऽस्तु नः श्रिये ॥ २ ॥
जिनः स पातु नाभेयो येन चामीकरच्छविः ।
क्षिप्तो विशुद्धये कायस्तपस्तीव्रहुताशने ॥ ३ ॥
जिनः स जयतां देवः संसारलवणार्ण्णवे ।
तपसा ज्वलता यस्य वाडवज्वलनायितम् ॥ ४ ॥

पत्र २/२ —

अथ कविः—

कवेः श्रीवामदेवस्य कामदेवस्य धन्विनः ।
वाणी च पंचबाणीव न लग्ना कस्य मानसे ॥ १ ॥

कवींद्राश्च करींद्राश्च मदमंथरगामिनः ।
वने वा स्थातुमिच्छंति भवने वाऽवनीभृतः ॥ २ ॥

कवेः श्रीकालिदासस्य तस्य किं स्तुमहे वयम् ।
यस्य काव्यत्रयीं श्रुत्वा मर्त्योऽपि विबुधो भवेत् ॥ ३ ॥

स्तोतुमेकं कविं न श्रीवाल्मिकिमृषयो विदुः ।
द्वितीयो यस्य नास्त्येव स कथं प्रथमः कविः ॥ ४ ॥

स एव पदविन्यासस्ता एवाक्षरपंक्तयः ।
वक्त्रे वक्त्रे मनुष्याणां क्वापि क्वापि विदग्धता ॥ ५ ॥

अन्तः—

अथ चेच्चेतनावानप्युच्चैर्न हसति स्वतः ।
ततः स तत्त्वतः सत्यं मृत एव श्वसन्नपि ॥ ६ ॥

कंठशोषकरैः किं वाऽपरैः प्रलपितैरपि ।
मूर्त्तिमानिव यो हास्यरसो धात्रा विनिर्मितः ॥ ७ ॥

तेनायं **सूक्तिरत्नानां सत्कोशः** समसूत्र्यत ।
पठ्यतां कृतिभिस्तावद्यावदिंदुदिवाकरौ ॥ ८ ॥

इति **सूक्तिरत्नकोशः** ॥ छ ॥ ग्रं. ६१३

अधिकार	पद्यसंख्या	अधिकार	पद्यसंख्या
१ मंगल	१	११ शांतः	३८
२ जिनस्तुतिः	७	१२ स्त्रीप्रशंसा	३७
३ हरः	१२	१३ विरहिणी	६९
४ हरिः	८	१४ योगिप्रक्रमः	१०
५ कविः	१४	१५ सिंहप्रक्रमः	१३
६ काव्यं	८	१६ वर्षा	८
७ सुजनः	१०	१७ नीतिः	६२
८ खलः	२५	१८ कृपणः	११
९ समस्याः	१८	१९ दैवम्	१०
१० नृपः	३९	२० वैद्यकम्	९

अधिकार	पद्यसंख्या	अधिकार	पद्यसंख्या
२१ वीरः	१५	४२ कमलं	४
२२ प्रकीर्णकं	१७	४३ समुद्रः	४
२३ पुत्रः	९	४४ सोमः	४
२४ सख्युपहासः	९	४५ प्रदोषः	६
२५ हास्यं	११	४६ कर्म	६
२६ चाटुपद्धतिः	८	४७ माया	२
२७ गुणाः	७	४८ चातकः	२
२८ तपः	६	४९ बकः	१
२९ विद्या	४	५० कोकिलः	२
३० उदाराः	५	५१ अगस्तिः	३
३१ रविः	६	५२ शृंगारः	१
३२ सरः	१	५३ अद्भुतः	१
३३ मृगः	१	५४ नृपोपालंभः	२
३४ धनिनः	८	५५ पृथ्वी	२
३५ दरिद्री	८	५६ नगरं	३
३६ स्वानुभवः	३	५७ प्रभातं	३
३७ वसंतः	९	५८ श्रीः	१
३८ ग्रीष्मः	३	५९ सुरतं	२
३९ मेघः	२	६० दयितस्यागमनं	२
४० शरत्	४	६१ उपसंहारः	८
४१ हेमंतः	५	इति सूक्तिरत्नकोशः ॥ छ॥ ग्रं. ६१३	

(2) Subhāṣitasaṅgraha (२) सुभाषितसङ्ग्रह

Folios – 37–97 Size – 13 × 1.7 inches
Language – Sanskrit Condition – Good
Age of MS. – c. First half of 15th cent. V. S.

आदिः—

यदपसरति मेषः कारणं तत्प्रहर्तुं मृगपतिरपि कोपात् संकुचत्युत्पतिष्णुः ।
हृदयनिहितवैरा गूढमंत्रप्रचाराः किमपि विगणयंतो बुद्धिमंतः सहंते ॥ १ ॥

अन्तः—

जर्जरिते सति हृदये स्मरशरसंघातघातसंपातैः ।
जलमिव गलति विवेकः कृत्याकृत्येषु नो कस्य ॥ १३ ॥ छ ॥ श्री ॥

विषय	पद्यसंख्या	विषय	पद्यसंख्या
१ सुभाषितानि	१-२५	१४ प्रकीर्णकान्योक्तिः	३४
निंदा	२६-३७	१५ ऋतवः	५
स्तुतिः	३८-४५	१६ धर्मः	४२
निंदास्तुतिः	४६-५४	१७ सत्पुरुषः	६१
स्तुतिनिंदा	५५-७४	१८ कुलस्त्री	१९
२ ?	७५	१९ पुत्रः	२२
३ ?	६८	२० दानं	९
४ विशुद्धतेजः	१३	२१ उपकारी	९
५ ?	२	२२ प्रकीर्णकं	५६
६ अन्योक्तिः	२२	२३ वैराग्यं	५१
७ चंद्रादित्यौ अन्योक्तिः	९	२४ भावना	४४
८ समुद्रः "	६	२५ वेश्या	२२
९ मेघः "	१४	२६ गुणाः	९
१० वायुः "	३	२७ नीतिः	६९
११ पर्वतः "	३	२८ जननी	५
१२ गजः "	२	२९ लक्ष्मीः	४९
१३ सिंहः "	४	३० स्मरः	१३

*

No. 266 : (1) Lokasaṃvyavahārapravṛttikāvya-Subhāṣitāvalī

(१) लोकसंव्यवहारप्रवृत्तिकाव्य —सुभाषितावली

Folios – 1-25
Extent – Āryās 281
Language – Sanskrit
Size – 12.2 × 1.7 inches
Author – Raviguptācārya
Condition – Good
Age of MS. – c. Latter half of 12th cent. V. S.
General Remarks – Folio 1 is worm-eaten.

आदि :—

....ता विमुक्ताश्च ।
याति भुवनं समंताचे केऽपि नमः सदा तेभ्यः ॥ १ ॥

ज्ञात्वा यत् किंचिदपि प्राज्ञाः कृति.... .... ।
....णुनाऽपि रंध्रेण ॥ २ ॥

गुणदोषयोरकस्मात् पतति यथाभ्यासमेव लोकोऽयम् ।
निपतंति गृध्रहंसाः स्म.... .... ॥ ३ ॥

....पक्रुतौ खलसत्पुरुषौ न तृप्तिमायातः ।
ग्रसते हि तमो भुवनं सविताऽपि सदा प्रकाशयति ॥ ७ ॥

परमर्मघट्टनादिषु खलस्य यत्कौशलं न तत्कृत्ये ।
यत्सामर्थ्यमुपहतौ विषस्य तन्नोपकाराय ॥ ८ ॥

आगमयत्यतियत्नात् परदोषान् सज्जनोऽपि नीच इव ।
किंतु विशेषणमनयोः पातुं सुजनः खलो वक्तुम् ॥ ९ ॥

शठचरितैरेव जना भृशमुपतप्ताः स्मरंति साधूनाम् ।
अभिलषति शशिनमधिकं दिनकरकरतापितो लोकः ॥ १० ॥
उद्युक्तः परभेदे यथा खलः सज्जनस्तथा संधौ ।
छिद्रं करोति सूची सपदि पिधत्ते तदनु तंतुः ॥ ११ ॥

अन्तः पत्र २५ —

इति जगति विचित्रदोषवह्निः क्षतशुभबीजगुणांकुरे प्रसूतौ ।
उपचिनुत यशांसि नैति यावत् त्रिभुवनघस्मरमृत्युवज्रपातः ॥ ७४ ॥

केनांजितानि नयनानि मृगांगनानां कश्चोत्पलेषु दलसंततिमाचिनोति ।
को वा करोति रुचिरांगरुहान् मयूरान् को वा ददाति विनयं हि कुलोद्गतानाम् ॥ छ ॥

लोकसंव्यवहारप्रवृत्तिर्नाम काव्यं । कृतिराचार्यरविगुप्तस्य ॥
साहसिकत्वं गुण इति यल्लघवः कल्पयंति तद्युक्तम् ।
गुंजाफलेषु दृष्टा प्रवालकाशा पुलिंद्राणाम् ॥

चिरपरिचयाद् गुणा अपि वैमुख्यं कल्पयंति सत्त्वानाम् ।
अतितृषिता अपि सलिलं पिबंत एवापरज्यंते ॥

अनुपायेन नियुक्ताः संतोऽपि न साधयंति कार्याणि ।
ऋजवोऽपि शरा लक्ष्यं न यांति विपरीतसंधानात् ॥
उच्चैः पदमधितिष्ठन् लोकस्तत्त्वेषु मुह्यति प्रायः ।
विषममपि पश्यति समं पर्वतशिखराग्रमारूढः ॥ २८१ ॥

(2) Subhāṣitāvalī (२) सुभाषितावली

Folios – 26–33
Size – 12.2 × 1.7 inches
Language – Sanskrit
Condition – Good
Age of MS. – c. Latter half of 12th cent. V. S.
General Remarks – Incomplete

आदिः—

जयति यशोदापुत्रः प्रसभं निहतः स येन कंस इति ।
आनंदयंतु युष्मान् गोकुलमुखनिर्गता वाचः ॥ १ ॥
उपविष्टः स्वे भवने सदसिद्धा वच्मि को मम स्वामी ।
नन्वेष लोकवादः सर्वत्र गृहे गृही राजा ॥ २ ॥
कश्चित् सुतमिदमूचे गृहधुरमधितिष्ठ वत्स यामि वनम् ।
गृहधूर्द्धरणसमर्थे पुत्रे श्रेयो वनान्नान्यत् ॥ ३ ॥
वरमन्ध-मूक-बधिरः पश्यति परुषाभिधानमिह नान्धः ।
न वदति परुषं मूकः कुप्यति परुषेण नो बधिरः ॥ ४८ ॥
स्वल्पमपि देहि काले स्यात् तद् बह्वप्यकालमत्यल्पम् ।
सर्वत्र देहि पात्रे न दानशौण्डो विचार्येति ॥ ५० ॥
यत्नं कुरु धनहेतोः पातकसदृशं वदन्ति विधनत्वम् ।
परिहरति जनो दूरात् पातकमिव धनपरिहीणम् ॥ ५६ ॥

अन्तः—

इत्युक्तवंतमुचितं पितरं ययाचे त्वं तात तावदिह तिष्ठ मुनिव्रतेन ।
यावद्भवामि निपुणो गृहकर्म कर्तुं पश्चाद्गमिष्यसि स चापि ततोऽवतस्थे ॥९७॥

*

No. 267: (1) Subhāṣitapadyasaṅgraha
(१) सुभाषितपद्यसङ्ग्रह

Folios – 5
Language – Prakrit
Age of MS. – c. First half of 14th cent. V. S.
Extent – Gāthās 90
Size – 13 × 2 inches
Condition – Good

आदिः—

किं भणिमो नवजुवईण ताण सव्वंगचंगिमसुहस्स ।
दिट्ठी तिभायफंसे वि जाणममयं पि हु नँ किं पि ॥ १ ॥

गयनेवच्छा वच्छे अइदुसहा तं सि तरुणनयणाण ।
वम्महकरसंगहिया निप्पडिया [ख ?]व्वखग्गलया ॥ २ ॥

दिट्ठीए तस्स ससहरकरससिलज्झ लासलोणाए(?) ।
बाला ससिमणिबाउल्लिय व्व सेउल्लिया जाया ॥ ३ ॥

नवसंगरंगनट्टावएण नच्चाविया तहा अहयं ।
मामि महं चिय हिययं न विम्हयं जेण पम्हुसइ ॥ ४ ॥

(2) Caityavandanā-Vandanaka-Pratyākhyānagāthā

(२) चैत्यवंदना–वंदनक–प्रत्याख्यानगाथा

Folios – 23-32
Language – Prakrit
Age of MS. – c. First half of 14th cent. V. S.
Size – 13.7 × 1.5 inches
Condition – Good

*

No. 268 : Nirbhayabhīmavyāyoga निर्भयभीमव्यायोग

Folios – 20-31
Language – Prakrit, Sanskrit
Author – Rāmacandrasūri
General Remarks – Complete.
Size – 13.7 × 2 inches
Condition – Good
Age of MS. – 1306 V.S.

आदिः—

ॐ ॥ तपोभिर्दुस्तपैर्येन संतप्यात्मानमूर्जिताः ।
जिता रागादयस्तस्मै कस्मैचित् प्रणिदध्महे ॥ १ ॥

(नान्द्यन्ते)

सूत्रधारः—(सविनयम्) भो भोः स्फुरितभाग्यप्रागल्भ्याः सभ्याः ! किमपि वो विज्ञपयामि अकाण्डप्रसन्नचेतसा तत्रभवतां भवतां सोऽयमिदानीमुपनीतप्रमोदप्रकर्षः । यतः–

सूक्तयो रामचन्द्रस्य पूर्णेन्दुः कलगीतयः ।
स्वातन्त्र्यमिष्टयोगश्च पंचैता हर्षवृष्टयः ॥ १ ॥

अन्तः—

पुरुषः—इदमस्तु—

भूयासुः सत्कवीनां रसरसनपराः काव्यवाचः प्रवाचः
प्रत्याशं यान्तु हेलाविफलितसुजना दुर्जना नाशमाशु ।
धर्मः पुष्णातु वृद्धिं कुरुकुलकमलारामचन्द्रः सुधार्द्रां
प्राप्य स्वातंत्र्यलक्ष्मीमनुभवतु मुदं शाश्वतीं भीमसेनः ॥

समाप्तोऽयं निर्भयभीमनामा व्यायोगः । कृतिरियं प्रबन्धशतकर्त्तुर्महाकवेः रामचन्द्रस्य ॥

यादृशं पुस्तके दृष्टं तादृशं लिखितं मया ।
यदि शुद्धमशुद्धं वा मम दोखो न दीयते ॥

संवत् १३०६ वर्षे भाद्रवा वदि ६ रवावद्येह श्रीमहाराजकुल **श्रीउदयसिंहदेव**-कल्याणविजयराज्ये **निर्भयभीमनामा** व्यायोगो लिखित इति ॥ शुभं भवतु लेखक-पाठकयोः ॥

*

No. 269 : Nyāyāvatāravṛtti **न्यायावतारवृत्ति**

Folios – 106
Language – Sanskrit
Author – Siddhavyākhyātā

Size – 15 × 2 inches
Condition – Good
Age of MS. – c. First half of 13th cent. V.S.

आदिः—

॥ नमो वाग्देवतायै ॥

अवियुतसामान्यविशेषदेशिनं वर्द्धमानमानम्य ।
न्यायावतारविवृतिः स्मृतिबीजविवृद्धये क्रियते ॥

तस्य चेदमादिवाक्यम् । प्रमाणेत्यादि । प्रमाणव्युत्पादनार्थमिदमारभ्यते ॥ छ ॥

अन्तः—

स्याद्वादकेसरिसुभीषणनादभीतेरुत्त्रस्तलोलनयनान् प्रपलायमानान् ।
हेतुर्नयाश्रितकुतीर्थिमृगाननन्यत्राणान् विहाय जिनमेत्य तमाश्रयध्वम् ॥

भक्तिर्मया भगवति प्रकटीकृतेयं तच्छासनांशकथनान्न मतिः स्वकीया ।
व्यामोहतो यदिह किंचिदभूदसाधु तत्साधवः कृतकृपा मयि शोधयंतु ॥
न्यायावतारविवृतिं विविधां विधित्सोः **सिद्धः** शुभो य इह पुण्यचयस्ततो मे ।
नित्यं परार्थकरणोद्यतमा भवांतात् भूयाज्जिनेंद्रमतलंपटमेव चेतः ॥

इति न्यायावतारवृत्तिः समाप्ताः ॥ छ ॥ मंगलं महाश्रीः ॥ छ ॥ शुभं भवतु ॥ छ ॥

*

No. 270 : (1) Nyāyapraveśapañjikā (१) न्यायप्रवेशपञ्जिका

Folios – 119
Language – Sanskrit
Author – Pārśvadevagaṇi
Date of Composition – 1169 V. S.
Size – 14.5 × 1.7 inches
Condition – Good
Age of MS. – 1318 V. S.

प्रथमपत्रप्रथमपृष्ठिकायाम्—

स्वार्थं पुस्तिकालेखनस्य प्रतिषेधानंतरं यः कोऽपि पुस्तिकां लेखयति तेन सर्व-साधारणमेव लेखयितव्येति व्यवस्था ॥ छ ॥ अत इयं **न्यायप्रवेशकन्यायावतार टिप्पनक पुस्तिका** अभिनवलिखितेति सर्वगच्छसाधारणा श्री**मज्जिनसिंहसूरीणां**। श्री**वीरसिंहसूरीणां**।

ग्रन्थादिः

॥ नमो नमोऽर्हद्भ्यः ॥

दुर्वारमारकरिकुंभतटप्रभेदकंठीरवं जिनपतिं वरदं प्रणम्य ।
न्यायप्रवेशकमिति प्रथिते सुशास्त्रे प्रारभ्यते तनुधियाऽपि हि पंजिकेयम् ॥१॥
येऽवज्ञां मयि विदधुः किंचन जानंति तानपास्यैषः ।
मत्तोऽपि जडमतीनामुपकाराय प्रयासो मे ॥ २ ॥

इह हि शिष्टानामयमाचारो यदुत शिष्टाः कचिदिष्टे प्रवृत्तिमभिलषंतो विघ्नविनायकोपशांतये इष्टदेवतानमस्कारपूर्वकं प्रवर्त्तन्ते ।

अंतः—

न्यायस्याधिगमः परिज्ञानं तेन यत् सुखं तस्य रसप्रकर्षावस्थानं लभतां प्राप्नुयात् । भव्यो मुक्तिगमनयोग्यो जनो लोक इति ॥ छ ॥ न्यायप्रवेशपंजिका समाप्तेति ॥ छ ॥

न्यायप्रवेशशास्त्रस्य सद्वृत्तेरिह पंजिका ।
स्वपरार्थं दब्धा स्पष्टा पार्श्वदेवगणिनाम्ना ॥ १ ॥

ग्रहरसरुद्रैर्युक्ते विक्रमसंवत्सरेऽनुराधायाम् ।
कृष्णायां च नवम्यां फाल्गुनमासस्य निष्पन्ना ॥ २ ॥
न्यायप्रवेशविवृतेः कृत्वेमां पंजिकां यन्मयाप्तम् ।
कुशलमिह तेन लोको लभतामवबोधफलमतुलम् ॥ ३ ॥
यावल्लवणोदन्वान् यावन्नक्षत्रमंडितो मेरुः ।
खे यावच्चंद्रार्कौ तावदियं पंजिका जयतु ॥ छ ॥ छ ॥

सवत् १३१८ वर्षे माघ शुदि १ रवौ अद्येह श्रीमत् पत्तने लिखितेति ॥

(2) Nyāyāvatāraṭippanaka (२) न्यायावतारटिप्पनक

Folios – 120–194
Language – Sanskrit
Age of MS. – 1318 V. S.
Size – 14.5 × 1.7 inches
Condition – Good

आदिः—

॥ ॐ ॥

नत्वा श्रीवीरमेकांतध्वांतविध्वंसभास्करम् ।
वृत्तौ **न्यायावतारस्य** स्मृत्यै किमपि टिप्यते ॥ १ ॥

इहाभीष्टदेवतानमस्कारपुरस्सरमनुष्ठीयमानं समस्तमपि प्रायः प्रयोजनं निर्विघ्नां सिद्धिमध्यास्त इति मन्यमानो व्याख्यातेति प्रसिद्धः **सिद्धः** प्रथमार्द्धेन भगवतो वर्द्धमानस्वामिनो नमस्कारं तथाऽभिधेयादि प्रतिपत्तिमंतरेण क्वचिदपि प्रेक्षावतां प्रवृत्तिर्न स्यादित्युत्तरार्द्धेनाभिधेयप्रयोजने च प्रतिपादयन्नाह । अवियुतेत्यादि ।

अन्तः—

एवं ज्ञानविशेषात्मके नयप्रमाणे सामान्यज्ञानरूपेणाऽऽत्मना व्याप्येते इति ॥छा॥ ३२ लौकिकतीर्थिकादीनि लौकिका हलधरादयः । तीर्थिका वैशेषिकादयः । आदिशब्दाच्छेषपाखंडिपरिग्रहः । वासनादित इत्यादिशब्दाद्विप्रतारकवचनादिग्रहः ॥ छ ॥

कोऽयं नाथ जिनो भवेत्तव वशे उंहुं प्रतापी प्रिये
उंहुं तर्हि विमुंच कातरमनः सौर्यावलेपक्रियाम् ।
मोहो येन विनिर्जितः प्रभुरसौ तत्किंकराः के वय-
मित्येवं रतिकामजल्पविषये वीरो जिनः पातु वः ॥ छ ॥

संवत् १३१८ वर्षे माघ शुदि ६ शुक्रेऽद्येह श्रीमदणहिल्लपाटके ।

*

No. 271 : Nyāyāvatārasūtravṛtti with Ṭippaṇī

न्यायावतारसूत्रवृत्ति टिप्पणीसह

Folios – 151 Size – 14.5 × 1.7 inches
Language – Sanskrit Condition – Good
Author – Siddhavyākhyātā Age of MS. – c. First half of 14th cent. V. S.

*

No. 272 : Kuṭṭanīmata—Śumbhalīmata

कुट्टनीमत—शुम्भलीमत

Folios – 93 Size – 14.2 × 2 inches
Language – Sanskrit Condition – Good
Author – Dāmodaragupta Age of MS.– c. Latter half of 13th cent. V. S.

General Remarks – Incomplete. Folios 14-19, 47, 57, 58 missing.

आदि :—

॥ ॐ नमः शिवाय ॥

स जयति संकल्पभवो रतिमुखशतपत्रचुंबनभ्रमरः ।
यस्यानुरक्तललनानयनांतविलोकनं वसतिः ॥ १ ॥
अवधीर्य दोषनिचयं गुणलेशे सन्निवेश्य मतिमार्याः ।
शुंभल्यामतमेतद्दामोदरगुप्तविरचितं शृणुत ॥ २ ॥
अस्ति खलु निखिलभूतलभूषणभूता विभूतिगुणयुक्ता ।
युक्ताभियुक्तजनता नगरी वाराणसी नाम ॥ ३ ॥
अनुभवतामपि यस्यामुपभोगान् कामतः शरीरवताम् ।
शशधरखंडविभूषणदेहलयः किल न दुष्प्रापः ॥ ४ ॥
चंद्रविभूषितदेहा भूतिरताः सद्भुजंगपरिवाराः ।
वारस्त्रियोऽपि यस्यां पशुपतितनुतुल्यतां याताः ॥ ५ ॥

*

No. 273 : (1) Strīnirvāṇaprakaraṇa with Commentary

(१) स्त्रीनिर्वाणप्रकरण सटीक

Folios – 2-38 Size – 11.2 × 2 inches
Language – Sanskrit Condition – Good
Author – Śākaṭāyana Bhadantapāda Yāpanīya
Age of MS. – c. First half of 14th cent. V. S.
General Remarks – Folios 1, 9, 18, 34 missing.

अन्तः—

न च बाधकं विमुक्तेः स्त्रीणामनुशासकं प्रवचनं च ।
संभवति च मुख्येऽर्थे न गौण इत्यार्यिकासिद्धिः ॥

स्त्रीणां नास्त्येव निर्वाणमिति न शक्यं प्रतिपत्तुम्, बाधकप्रमाणाभावात् । तदायत्तो हि नास्तिताव्यवहारः । अस्तित्वे तु तस्यागमः प्रमाणमुक्तम् । न च तत्र स्त्रीशब्दस्यान्योऽर्थः शक्यते कल्पयितुं । तत्र प्रमाणाभावात् । न हि तत्र मुख्यार्थासंभवप्रतिपत्तिमंतरेण गौणार्थकल्पनाऽस्ति । गौणश्च स्त्रीशब्दः पुमर्थः । तस्मान्निःश्रेयसकामेनाविपरीतं शास्त्रार्थं प्रतिपद्यमानेनावश्यं स्त्रीनिर्वाणं प्रतिपत्तव्यमिति ॥ छ ॥ **स्त्रीनिर्वाणपरिच्छेदः समाप्तः** ॥ छ ॥ शुभं भवतु ॥

(2) Kevalibhuktiprakaraṇa with Commentary

(२) केवलिभुक्तिप्रकरण सटीक

Folios – 39-61
Size – 11.2 × 2 inches
Language – Sanskrit
Condition – Good
Age of MS. – c. First half of 14th cent. V. S.
General Remarks – Folios 41, 47-50 missing.

आदिः—

एवं स्त्रीनिर्वाणं प्रतिपाद्येदानीं केवलिभुक्तिं प्रतिपिपादयिषुः पूर्ववद्बाधकप्रमाणाशंकापरिहारायोपक्रमते । अस्ति च केवलिभुक्तिः समग्रहेतुर्यथा पुरा नास्ति केवलिभुक्तिः । विकलकारणत्वादित्यसिद्धो हेतुः । यत्पूर्वमकेवल्यवस्थायां भुक्तिकारणं तत्केवल्यवस्थायामपि चिरविहारिणो भगवतः केवलिनोऽविकलमास्ते । एवं द्विविधं भुक्तेः कारणं बाह्यमाभ्यंतरं च । बाह्यं द्रव्यादिवत् तत् तावदास्ते । न तत्र विप्रतिपत्तिः । यस्त्वाभ्यंतरः सपर्याप्तिवेद्यतैजसदीर्घायुष्कोदयो हेतुः । भुक्तस्याहारस्य तैजसा मृदूकृतस्य खलरसभावादुत्तरोत्तरपरिणामः कारणं । यतः शरीरेन्द्रियादिनिष्पत्तिः सा पर्याप्तिर्नाम कारणं ।

*

No. 274 : (1) Bṛhajjātaka (१) बृहज्जातक

Folios – 60
Extent – Kāvyas 400
Language – Sanskrit
Size – 15 × 2.2 inches
Author – Varāhamihira
Condition – Good
Age of MS. – c. First half of 14th cent. V. S.

आदिः—

॥ ॐ नमः सूर्याय ॥

मूर्त्तित्वे परिकल्पितः शशिभृतो वर्त्माऽपुनर्जन्मना-
मात्मेत्यात्मविदां क्रतुश्च यजतां भर्त्तामरज्योतिषाम् ।
लोकांनां प्रलयोद्भवस्थितिविभुश्चानेकधा यः श्रुतौ
वाचं नः स ददात्वनेककिरणस्त्रैलोक्यदीपो रविः ॥ १ ॥

अन्तः—

इति द्रेक्काणाध्यायः पंचविंशतितमः समाप्तः ॥ छ ॥

आदित्यदासतनयस्तदवाप्तबोधिं
कापित्थके सवितृलब्धवरप्रसादः ।
आवंतको मुनिमतान्यवलोक्य सम्यक्
होरां **वराहमिहरो** रुचिरां चकार ॥

राशिप्रभेदो ग्रहयोनिभेदो वियोनिजन्माथ निषेककालः ।
जन्माथ सद्यो मरणं तदायुर्दशाविपाकोऽष्टकवर्ग संज्ञाः ॥ २ ॥
कर्माजीवो राजयोगा खयोगाश्चांद्रा योगा विग्रहाद्याश्च योगाः ।
प्रव्रज्यातो राशिशीलो च दृष्टिर्भावस्तस्मादाश्रयोऽथ प्रकीर्णः ॥ ३ ॥
नेष्टा योगा जातकं कामिनीनां निर्याणं स्यान्नष्टजन्मद्दकाणः ।
अध्यायानां विंशतिः पंचयुक्ता चत्वार्यस्मिन् वृत्तसंख्याशतानि ॥ ४ ॥

इति बृहज्जातकं समाप्तं ॥ छ ॥ मंगलं महाश्रीः ॥ छ ॥

(2) Lagnakuṇḍalikā—Lagnaśuddhi

(२) लग्नकुण्डलिका—लग्नशुद्धि

Folios – 17	Extent – Gāthās 129
Language – Prakrit	Size – 15 × 2.2 inches
Author – Haribhadrasūri	Condition – Good

Age of MS. – c. First half of 14th cent. V. S.

आदिः—

अवितहसव्वाएसं नमिउं चउवीसमं जिणवरेसं ।
वुच्छामि समासेणं लग्गं सुगुरूवएसेणं ॥ १ ॥

अन्तः—

इय सुंदरे वि लग्गे सुहसउणबलेण कुणसु कज्जाइं ।
अहव निमित्तबलेणं वयणमिणं **हारिभद्दो** त्ति ॥ २८ ॥

इय तिविहसुद्धिजुत्तं तीए विउत्तं च वन्निय लग्गं ।
जं किंचि इह अजुत्तं [वुत्तं] सोहिंतु तं विउसा ॥ २९ ॥

लग्नकुंडलिका समाप्ता ॥ छ ॥

*

No. 275 : Samayasāraśāstra with Ātmakhyātivyākhyā
समयसारशास्त्र आत्मख्यातिव्याख्यासह

Folios – 189
Size – 14.7 × 2 inches
Language – Sanskrit
Condition – Good
Age of MS. – c. Latter half of 13th cent. V. S.

आदिः—

॥ ॐ नमः परमात्मने ॥ नमो वीतरागाय ॥

नमः समयसाराय स्वानुभूत्या च काशते ।
चित्स्वभावाय भावाय समभावान्तरच्छिदे ॥ १ ॥

अनंतधर्मणस्तत्त्वं पश्यंती प्रत्यगात्मनः ।
अनेकांतमयी मूर्त्तिर्नित्यमेव प्रकाशताम् ॥ २ ॥

परपरिणतिहेतोर्मोहनाम्नोऽनुभावादविरतमनुभाव्य व्याप्तिकल्माषितायाः ।
मम परमविशुद्धिः शुद्धचिन्मात्रमूर्त्तेर्भवतु समयसारव्याख्ययैवानुभूतेः ॥

अथ सूत्रावतारः—

वंदित्तु सव्वसिद्धे धुवमचलमणोवमं गइं पत्ते ।
वोच्छामि समयपाहुडमिणमो सुअकेवलीभणियं ॥ १ ॥

अन्तः—

अविचलितचिदात्मन्यात्मनाऽऽत्मानमात्मन्यनवरतनिमग्नं धारयद् ध्वस्तमोहम् ॥ १ ॥
उदितममृतचंद्रज्योतिरेतत्समंताज्ज्वलतु विमलपूर्णं निःसपत्नस्वभावम् ॥ छ ॥

इति समयसारव्याख्यायामात्मख्यातौ नवमोऽङ्कः ॥

यस्माद् द्वैतमभूत् पुरा स्वपरयोर्भूतं यतोऽत्रान्तरं-
रागद्वेषपरिग्रहे सति मनो जातं क्रियाकारकैः ।

भुंजाना च यतोऽनुभूतिरखिलं खिन्ना क्रियायाः फलं
तद्विज्ञानघनौघमग्नमधुना किंचिन्न किंचित् किल ॥ छ ॥
इत्यात्मख्यातिनाम समयसारव्याख्या समाप्ता ॥ छ ॥

*

No 276: (1) Dharmabinduprakaraṇasūtra

(१) धर्मबिन्दुप्रकरणसूत्र

Folios – 50
Language – Sanskrit
Author – Haribhadrasūri
Size – 13 × 2 inches
Condition – Good
Age of MS. – c. beginning of 14th cent. V. S.

General Remarks – Folios 112-124, 126, 128, 150-155 missing.

आदिः—

॥ ॐ नमः सर्वज्ञाय ॥

प्रणम्य परमात्मानं समुद्धृत्य श्रुतार्ण्णवात् ।
धर्मबिंदुं प्रवक्ष्यामि तोयबिंदुमिवोदधेः ॥ १ ॥

अन्तः—

इति धर्मबिंदौ धर्मफलविधिः अष्टमोऽध्यायः समाप्तः ॥ छ ॥ कृतिराचार्य-हरिभद्रस्येति ॥ मंगलं महाश्रीः ॥

(2) Dharmabinduprakaraṇa with Commentary

(२) धर्मबिन्दुप्रकरण सटीक

Folios – 221
Language – Sanskrit
Author – Ācārya Haribhadra
Age of MS. – 1181 V. S.
Extent – Granthas 3000
Size – 12.7 × 1.7 inches
Commentator – Municandrasūri
Condition – Good

आदिः—

॥ ॐ नमः सर्वज्ञाय ॥

शुद्धन्यायवशायत्तीभूतसद्भूतसंपदे ।
पदे परे स्थितायास्तु श्रीजिनप्रभवे नमः ॥
जयंतु ते पुर्वमुनीशमेघा यैर्विश्वमाश्वेव हतोपतापम् ।
चक्रे बृहद्वाङ्मयसिंधुपानप्रपन्नतंगातिगभीरवृष्टैः ॥

यन्नामानुस्मृतिनयमयं सज्जनाश्चित्तचक्षुः-
क्षेपाद्दिव्यांजनमनुसरन् लब्धशुद्धावलोकः ।
सद्यः पश्यत्यमलमतिहृन्मेदिनीमध्यमग्नं
गंभीरार्थं प्रवचननिधिं भारतीं तां स्तवीमि ।
विदधामि **धर्मबिंदो**रतिविरलीभूतगर्भपदबिंदोः ।
भव्यजनोपकृतिकृते यथावबोधं विवृतिमेताम् ॥ छ ॥
प्रणम्य परमात्मानं समुद्धृत्य श्रुतार्णवात् ।
धर्मबिंदुं प्रवक्ष्यामि तोयबिंदुमिवोदधेः ॥ इति ॥

अन्तः—

इति **श्रीमुनिचंद्र**सूरिविरचितायां **धर्मबिंदुप्रकरणवृत्तौ** विशेषतो धर्मफलविधिरष्टमोऽध्यायः समाप्तः ॥

नाविष्कर्तुमुदारतां निजधियां वाचां न वा चातुरी-
मन्येनापि च कारणेन न कृता वृत्तिर्न वाऽसौ परम् ।
तत्त्वाभ्यासरतादुपात्तसुकृतोऽन्यत्रापि जन्मन्यहं
सर्वादीनवहस्तितोऽमलमना भूयासमुच्चैरिति ॥

इति श्री**मुनिचंद्र**सूरिविरचिता **धर्मबिंदुप्रकरणवृत्तिः समाप्ता** ॥ ग्रंथाग्रं सहस्र ३००० त्रीणि ॥ संवत् ११८१ वैशाख वदि १५ सोमे पा. **जसदेवेन** लिखितमिति । लेखकपाठककल्याणं भवतु ॥

*

No. 277 : <u>Upamitabhavaprapañcānāmasamuccaya</u>

उपमितभवप्रपञ्चानामसमुच्चय

Folios – 128 Extent – Granthas 1526
Language – Sanskrit Size – 13.5 × 1.7 inches
Author – Varddhamānasūri Condition – Good
Age of MS. – c. First half of 14th cent. V.S.

आदिः—

॥ ॐ नमः सर्वज्ञाय ॥

दुर्वारांतररागादिवैरिकरियूथमथनपंचास्यं ।
निर्वृतिनगरीनाथं नत्वा श्रीमन्महावीरं ॥ १ ॥

उपमितभवप्रपंचाप्रस्तावाष्टककथाविशेषाणाम् ।
नामसमुच्चयमात्मस्मृतये रचयामि परिपाठ्या ॥ २ ॥

अन्तः—

इत्युपमितभवप्रपंचायां श्रीवर्द्धमानसूरिविरचिते नामसमुच्चये पूर्वसूचितमीलकवर्णनो नाम अष्टमः प्रस्तावः ॥ ग्रं० २४० ॥ ग्रं० श्लोकसंख्या १५२६ ॥

नम्रोन्नम्रे यदस्मिन्नपि जगति पदांगुष्ठपीडां प्रपन्ना
स्वर्णाद्रिः क्षुभ्यदब्धेर्विमलितममृतैरभ्रमुल्लोचतीदम् ।
यत्ताराः स्वस्तिकंति क्षितितलमिलिताः यस्य जन्मोत्सवे तत्
कल्पोऽप्याकल्पकल्पः स नुदतु दुरितं वो महावीरदेवः ॥

भूभृत्प्रतिष्ठामधितिष्ठमानः श्रीमालवंशो न कुतोऽपि नीचः ।
संसेव्यमानोऽर्थिभिरुद्धतोऽप्यवष्टंभनाय प्रयतैः स जीयात् ॥

तस्मिन्नाम्नाऽस्ति वेल्लत्फल इति कलिना यो बहिष्कृत्य मुक्त-
स्तुच्छेनातुच्छमूर्त्तिः प्रणयिवितरणे कल्पशाखीव मर्त्त्यः ।

शंके पुण्यैकमार्गः कृतयुगसमयान्नास्ति पूर्वं तदस्मात्
नो चेत्तत्संततिः किं सुकृतिशतकृतारंभरेखेव लीली ॥

मोक्षस्य हेतुः प्रथमस्तथांशः प्रत्यर्थितंत्रं श्रुतधर्म एषः ।
श्रेयोऽर्थमेषोपमितिं व्यलीलिखल्लीलीसुता तस्य पितुस्तदेताम् ॥

संसारवार्द्धौ पततां जनानां स्फुरत्ययं हस्त इवाविमग्नः ।
आलंबनीयः श्रवणादिकृत्यैर्विलेखितो ग्रंथ इयं प्रशस्तिः ॥

मंगलमस्तु ॥ छ ॥ मंगलं महाश्रीः ॥ शुभं भवतु ॥ छ ॥

*

No. 278 : **Bhaktāmarastotra with Commentary**

भक्तामरस्तोत्र—सटीक

Folios – 28
Size – 13.5 × 2.2 inches
Language – Sanskrit
Condition – Good
Author – Mānatuṅgasūri
Commentator – Śāntisūri
Age of MS. – c. First half of 15th cent. V.S.

आदिः—

॥ ॐ नमो वीतरागाय ॥

वृत्तिं भक्तामरादीनां स्तवानां वच्मि यथोचितम् ।
संक्षेपान्मुक्तिलाभाय सुखबुद्धिप्रबुद्धये ॥ १ ॥

भक्तामर० काव्यद्वयपूर्ण छे.

अन्तः—

श्रीखंडेल्लकगच्छसम्बन्धिश्वेतांबरश्रीशान्तिसूरिविरचितमानतुंगाचार्यकविकृत-भक्तामराख्यसूत्रवृत्तिपरिसमाप्ता ॥ छ ॥

*

No. 279 : (1) Ṛṣabhapañcāśikā with Commentary

(१) **ऋषभपञ्चाशिका—सटीका**

Folios – 1–22
Language – Prakrit & Sanskrit
Author – Dhanapāla
Size – 11.7 × 1.7 inches
Condition – Good
Age of MS. – 1265 V.S.

आदिः—

जयजंतुकप्पपायव चंदायवरायपंकयवणस्स ।
सयलमुणिगामगामणि तिलोयचूडामणि नमो ते ॥ १ ॥

नमस्तुभ्यं जंतुकल्पपादप जगति विष्टपे जायंते प्रादुर्भवंति स्वोत्पत्तिस्थानेष्विति जंतवो जीवास्तेषां कल्पो मनोरथस्तत्पूरकः पादप इव कल्पपादपस्तस्य संबोधनम् ।

अंतः—

इय झाणग्गिपलीयकम्मिंधण बालबुद्धिणा वि मए ।
भत्तीए थुओ भवभयसमुद्दबोहित्थ बोहिफलो ॥ ५० ॥

व्याख्या—इत्युक्तेन प्रकारेण स्तुतो नमस्कृतो मया । किंविधेन । बालबुद्धिनाऽपि मंदमतिनाऽपि । हे ध्यानाग्निप्रदीप्तकर्मेंधन ध्यानाग्निना प्रदीप्तं ज्वलितं कर्मलक्षणमिंधनं येन तथोक्तस्तस्यामंत्रणं । पुनः किंविशिष्ट ? भवभयसमुद्रबोधिस्थसंसारोपद्रवाणां च यानपात्रं । बोधेः फलं यस्मात् स तथा गतरेवा भवभयसमुद्रबोधिस्थबोधिफलः तथा भव संपद्यस्व बोधिफलो बोधिजनक इति । ननु किमुपहासेन स्तुतौ, नेत्याह भक्त्या विशिष्ट-भावेन अनार्या च वक्रोक्त्या कविरात्मनोऽभिधा दर्शयति धनपाल इति ॥ छ ॥ मंगलमस्तु जिनशासनानुरक्तानाम् ॥

(2) Taporatnamālikāprakaraṇa

(२) तपोरत्नमालिकाप्रकरण

Folios – 22–29
Language – Prakrit
Author – Kulaprabhasūri
Age of MS. – 1265 V. S.

Extent – Gāthās 67
Size – 11.7 × 1.7 inches
Condition – Good

आदिः—

पढमंतिमे जिणिंदे वरिस-छमासे तवित्तु उक्कोसं ।
झोसियकम्मे नमिउं गुरूवइट्ठे तवे भणिमो ॥ १ ॥

इंदियतरलतुरंगमदमणं कामग्गिसमणजलवाहो ।
कम्मरयपडलपवणो पसिद्धिमूलं तवो जयउ ॥ २ ॥

उवहाण १ नाणपंचमि २ कल्लाणिग ३ नाणदंसणचरित्ते ४ ।
इंदियजओ ५ कसायज्जओ य ६ तह योगसुद्धी य ७ ॥ ३ ॥

अन्तः—

आगमओ विन्नेया कुसलेहिं तह गुरूवएसाओ ।
इह पुण सव्वेसिं चिय उवओगा भावओ नुत्ता ॥ ६५ ॥

कुल-लच्छि-पउम-हरि-सूर-रिद्धिपढमक्खराभिहाणेहिं ।
सिरिसुमइसिंहगणहरसीसेहिं विणिम्मियं एयं ॥ ६६ ॥

तवरयणमालियं जो धरेइ कंठंमि गुणगणानिवद्धं ।
सो सच्छंदं विलसइ सयावि सिवलच्छिवच्छयले ॥ ६७ ॥ छ ॥

संवत् १२६५ वर्षे माघ सुदि ८ बुधे समर्थितमिदम् ॥ छ ॥

सररसकरपरत्थे १२६५ वट्टंते वच्छरंमि सोमेण ।
जयजंतुकप्पपायवविज्जीकुलयं च परिलिहियं ॥ ६८ ॥

सिरि कुलपहगणनायगकवित्तकित्तीपवित्तयं कुलयं ।
अतुच्छलच्छिवच्छे भरुयच्छे सुट्ठु सम्मत्तं ॥ ६९ ॥

शुभं भवतु सदा ॥ छ ॥

*

No. 280: Dharmaratnaprakaraṇa with Commentary

धर्मरत्नप्रकरण सटीक

Folios – 338
Language – Prakrit & Sanskrit
Commentator – Devendrasūri
Condition – Dilapidated
Author – Śāntisūri
Age of MS. – c. First half of 14th cent. V.S.

General Remarks – Incomplete. The ms. is dilapidated in condition. Several folios are stuck together and spoilt.

*

No. 281 : Triṣaṣṭiśalākāpuruṣacaritamahākāvya Parvan II.
त्रिषष्टिशलाकापुरुषचरितमहाकाव्य-द्वितीय पर्व

Folios – 2–109
Author – Hemacandrācārya
Age of MS. – c. Latter half of 15th cent. V. S.
Size – 18.2 × 2.5 inches
Condition – Fair

*

No. 282 : (1) Āvaśyakaniryukti
(१) आवश्यकनिर्युक्ति

Folios – 65
Language – Prakrit
Author – Bhadrabāhuswāmin
Size – 10 × 2 inches
Condition – Fair
Age of MS. – c. Latter half of 14th cent. V.S.

General Remarks – Incomplete

(2) Karmaprakṛti : (२) कर्मप्रकृति

Folios – 30-61
Language – Prakrit
Author – Śivaśarman
Age of MS. – c. First half of 14th cent. V. S.
General Remarks – Incomplete
Extent – Gāthās 226-446
Size – 8.5 × 2 inches
Condition – Good

(3) Karmavipāka : (३) कर्मविपाक

Folios – 11-17
Language – Prakrit
Author – Gargarṣi
Size – 8.5 × 2 inches
Condition – Good
Age of MS. – c. Latter half of 14th cent. V. S.

General Remarks – Incomplete

(4) Purāṇaślokasaṅgraha
(४) पुराणश्लोकसंग्रह

Folios – 43-45
Language – Sanskrit
Age of MS. – c. First half of 15th cent. V. S.
Size – 7.5 × 1.7 inches
Condition – Good

*

No. 283 : (1) Navapadaprakaraṇa (१) नवपदप्रकरण

Folios – 104–120
Extent – Gāthās 7–136
Language – Prakrit
Size – 12.2 × 2.2 inches
Author – Jinacandragaṇin
Condition – Good
Age of MS. – c. Latter half of 15th cent. V. S.
General Remarks – Incomplete

(2) Vandanakaniryukti
(२) वंदनकनिर्युक्ति

Folios – 22
Extent – Up to Gāthās 200
Language – Prakrit
Size – 13.2 × 2 inches
Author – Bhadrabāhuswāmin
Condition – Good
Age of MS. – c. Latter half of 15th cent. V. S.
General Remarks – Incomplete

(3) Palyopamopavāsavidhi
(३) पल्योपमोपवासविधि

Folios – 2-5
Size – 13 × 2 inches
Language – Sanskrit
Condition – Good
Age of MS. – 1260 V. S.

अन्तः—

रजोमलेन लिप्तस्य यथा तोयेन निर्मलः ।
तथोपवासतोयेन आत्मा भवति निर्मलः ॥
जन्मान्तरकृतं पापं संचितं बहुजन्मसु ।
मुच्यते उपवासेन गिरिर्वज्रहतो यथा ॥

॥ **श्रीमद्वृषभनाथजिनेन भाषितः पल्योपमोपवासविधिः समाप्तः** ॥ पठितेन पल्यफलं भवति । श्रुतेन तथाऽभ्यधिकम् । लिखितेन सहस्रगुणम् । कृतोपवासेन अनन्तफलं भवति ॥ छ ॥ चतुर्विंशतितीर्थकराणां यथाशक्ति स्नपनं कार्यम् । श्रुतज्ञानस्य पूजा कार्या । चतुर्विधसंघस्य दानादिपूजा करणीया ॥ छ ॥ संवत् १२६० वर्षे अश्विनिवदि त्रितीयायां बृहष्पतिदिने ॥ छ ॥

(4) Karmastavakarmagrantha–Ancient
(४) कर्मस्तवकर्मग्रन्थ–प्राचीन

Folios – 192–197
Extent – Gāthās 57
Language – Prakrit
Size – 13 × 2 inches
Age of MS. – c. End of 15th cent. V. S.

(5) Karmavipākakarmagrantha-Ancient
(५) कर्मविपाककर्मग्रन्थ-प्राचीन

Folios – 197–219
Extent – Gāthās 168
Language – Prakrit
Size – 13 × 2 inches
Author – Gargarṣi
Condition – Good
Age of MS. – c. End of 15th cent. V. S.

(6) Śatakakarmagrantha-Ancient
(६) शतककर्मग्रन्थ-प्राचीन

Folios – 219–236
Extent – Gāthās 110
Language – Prakrit
Size – 13×2 inches
Author – Śivaśarman
Condition – Good
Age of MS. – c. End of 15th cent. V. S.
General Remarks – Folios 227–235 missing.

(7) Saptatikākarmagrantha
(७) सप्ततिकाकर्मग्रन्थ

Folios – 236–250
Extent – Up to Gāthās 85
Language – Prakrit
Size – 13 × 2 inches
Age of MS. – c. End of 15th cent V. S.
Condition – Good

(8) Praśnottararatnamālikā
(८) प्रश्नोत्तररत्नमालिका

Folios – 90–92
Extent – Āryās 28
Language – Sanskrit
Size – 12.7 × 1.7 inches
Author – Vimalācārya
Condition – Good
Age of MS. – c. First half of 15th cent. V. S.

(9) Aśubhadhyāna Āharaṇa Prakaraṇa
(९) अशुभध्यान आहरण प्रकरण

Folios – 2–5
Extent – Up to Gāthās 32
Language – Prakrit
Size – 11 × 1.7 inches
Age of MS. – c. Latter half of 15th cent. V. S.
Condition – Good

No. 284 : Sthānāṅgasūtra : स्थानांगसूत्र

Folios – 4–146
Size – 13.2 × 2.2 inches
Language – Prakrit
Condition – Good
Age of MS. – c. Latter half of 13th cent. V. S.
General Remarks – Incomplete. Many folios missing.

*

No. 285 : Bhagavatīsūtra : भगवतीसूत्र

Folios – 5–163 Size – 13.7 × 2.5 inches
Language – Prakrit Condition – Good
Age of MS. – c. Latter half of 13th cent. V. S.
General Remarks – Incomplete. Folios 111-154 and several others missing.

*

No. 286 : Bṛhatkṣetrasamāsaprakaraṇa with Commentary
बृहत्क्षेत्रसमासप्रकरण सटीक

Folios – 62–111 Size – 15 × 2.2 inches
Language – Prakrit & Sanskrit Condition – Good
Author – Jinabhadragaṇin Kṣamāśramaṇa
Commentator – Ācārya Malayagiri Age of MS. – First half of 13th cent. V. S.

*

No. 287 : Āgamikavastuvicārasāraprakaraṇa with Commentary
आगमिकवस्तुविचारसारप्रकरण सटीक

Folios – 12–41 and 93–121 Size – 14 × 2.2 inches
Age of MS. – c. First half of 14th cent. V. S. Condition – Good

*

No. 288 : (1) Kalpasūtra : Paryuṣaṇākalpa
(१) कल्पसूत्र–पर्युषणाकल्प

Folios – 7–99 Extent – Granthas 1216
Language – Prakrit Size – 13.5 × 2 inches
Author – Bhadrabāhuswāmin Condition – Fair
Age of MS. – c. Latter half of 14th cent. V. S.

(2) Kālikācāryakathā
(२) कालिकाचार्यकथा

Folios – 99-130 Size – 13.5 × 2 inches
Language – Prakrit Condition – Fair
Age of MS. – c. Latter half of 14th cent. V. S.
General Remarks – Incomplete. The folios are stuck together and thus the ms. is spoilt.

*

No. 289 : Bṛhatkṣetrasamāsaprakaraṇa with Commentary
बृहत्क्षेत्रसमासप्रकरण–सटीक

Folios – 200–270 Extent – Granthas 7660
Language – Prakrit & Sanskrit Size – 17.2 × 4.5 inches
Author – Jinabhadragaṇin Kṣamāśramaṇa
Commentator – Ācārya Malayagiri Condition – Good
Age of MS. – 1466 V. S.
General Remarks – Complete

आदिः—

जयति **जिनवचन**मवितथममितगभीरार्थं....नयकलितम् ।
अजितं परतीर्थिगणैः शिवसुखफलदायि परमशिवम् ॥ १ ॥

कलिकालेऽपि यथास्थितजिनसिद्धांतप्रकाशकरणेन ।
जयति भरतैकदीपो **जिनभद्र**गणिक्षमाश्रमणः ॥ २ ॥

विवृणोमि यथाशक्ति **क्षेत्रसमासं** समासतः स्पष्टम् ।
यदवगतौ.... .... ति श्रुतविदः परमाम् ॥ ३ ॥

इह **जिनभद्र**गणिक्षमाश्रमणो मंदमेधसामवबोधाय **सकलजंबूद्वीपप्रज्ञप्त्या**दिशास्त्र-संक्षेपं समुद्धर्तुकामोऽविघ्नेनेष्टप्रसिद्ध्यर्थमिष्टदेवतानमस्कारं प्रेक्षावतां प्रवृत्त्यर्थमभिधेयादिकं च प्रतिपिपादयिषुरिदमाह ॥ छ ॥

नमिऊण सजलजलहरनिभस्सणं वद्धमाणजिणवसहं ।
समयक्खेत्तसमासं वोच्छामि गुरूवएसेणं ॥

अन्तः—

गाहाणं छच्च सया सत्तत्तीसा य होंति पडिपुण्णा ।
खेत्तसमासपगरणं निद्दिट्ठं सव्वसंखाए ॥ छ ॥

इदं क्षेत्रसमासप्रकरणं सर्वसंख्यया निर्दिष्टं गाथानां षट् शतानि सप्तत्रिंशदधिकानि परिपूर्णानि भवंति ६३७ । अधुना क्षेत्रसमासप्रकरणे पठनाय श्रवणाय च वृत्तानामुत्तरफलं संप्राप्तिविषयमाह ॥ छ ॥

समयक्खेत्तसमासं जो पढइ जो य णं निसामेइ ।
तेसिं सुयंगदेवी उत्तमसुयसंपयं देउ ॥

योऽमुं क्षेत्रसमासं सम्यग्भावसारं पठति यश्च निशामयत्याकर्णयति तेभ्यः श्रुतांगदेवी द्वादशांगश्रुतरूपिणी देवी उत्तमां श्रुतसंपदं ददातु ॥ छ ॥

जिनवचनगतं विषमं भावार्थं यो विवेच्य शिष्येभ्यः ।
इत्थमुपादिशदमलं परोपकारैककृतचेताः ॥

तं नमत बोधजलधिं गुणमंदिरमाखिलवाग्मिनां श्रेष्ठम् ।
चरणश्रियोपगूढं **जिनभद्रगणिक्षमाश्रमणम्** ॥

वाचः क्व तस्य गंभीराः परभागमुपागताः ।
क्व चाहं जडधीरेष स्वल्पशास्त्रकृतश्रमः ॥

तथापि गुरुपादारविंदद्वंद्वप्रसादतः ।
जातकिंचिन्मतिस्फूर्त्तिरेनां टीकां व्यधामहम् ॥

यद्गदितमल्पमतिना जिनवचनविरुद्धमत्र टीकायाम् ।
विद्वद्भिस्तत्त्वज्ञैः प्रसादमासाद्य तच्छोध्यम् ॥

इममतिगंभीरतरं **क्षेत्रसमासं** विवृण्वता कुशलम् ।
यदवापि **मलयगिरिणा** सिद्धिं तेनाश्नुतां लोकः ॥

अर्हतः शरणं सिद्धान् शरणं संयतानपि ।
शरणं जिननिर्दिष्टं धर्मं शरणमाश्रितः ॥
अर्हंतो मंगलं सिद्धा मंगलं मम साधवः ।
मंगलं मंगलं धर्मं स्वान्मंगलमशिश्र.... ॥ छ ॥

इति मलयगिरिरचिता क्षेत्रसमासटीका पारमुपागमदिति ॥ छ ॥ श्रीस्तु ॥ छ ॥ ग्रंथाग्रं ७६६० सप्तसहस्राणि षट् शतानि षष्ट्यधिकानि ॥ छ ॥

संवत् १४९६ वर्षे **श्रीखरतरगच्छे** श्रीजिनराजसूरिपट्टे **श्रीजिनवर्धनसूरि**विद्यमाने सति **श्रीपत्तने** पुस्तकं लिखापितम् ॥

*

No. 290 : Āvaśyakasūtra-Śiṣyahitāvṛtti Part II

आवश्यकसूत्र–शिष्यहितावृत्ति–द्वितीयखंड

Folios – 219
Size – 17.2 × 3 inches
Language – Prakrit & Sanskrit
Condition – Good
Author – Ācārya Haribhadrasūri
Age of MS. – 1492 V. S.
General Remarks – The ms. is written on paper.

॥ ॐ ॥

आदिः—

अत्र सूत्रस्पर्शकनिर्युक्त्यवसरः । सा च प्राप्तावसराऽपि नोच्यते । यस्मादसति सूत्रे कस्यासाविति । ततश्च सूत्रानुगमे वक्ष्यामः । आह यद्येवं किमिति तस्याः

खल्विहोपन्यासः। उच्यते। निर्युक्तिमात्रसामान्यात्। एवं सूत्रानुगमोऽप्यवसरप्राप्त एव। तत्र च सूत्रमुच्चारणीयम्।

अन्तः—

शिष्यहितायां प्रत्याख्यानविवरणं समाप्तं ॥ छ ॥

व्याख्यायाध्ययनमिदं यदवाप्तमिह शुभं मया पुण्यम्।
शुद्धं प्रत्याख्यानं लभतां भव्यो जनस्तेन ॥

समाप्ता चेयं शिष्यहितानामाऽऽवश्यकटीका। कृतिः **सितांबराचार्यजिनभट**-निगदानुसारिणो **विद्याधरकुल**तिलकाचार्य**जिनदत्त**शिष्यस्य धर्मतो **जाइणीमहत्तरा**सूनोरल्प-मतेराचार्य**हरिभद्र**स्य।

यदिहोत्सूत्रमज्ञानाद् व्याख्यातं तद्बहुश्रुतैः।
क्षन्तव्यं कस्य सम्मोहश्छद्मस्थस्य न जायते ॥

यदर्जितं विरचयता सुबोध्यां पुण्यं **मयाऽऽवश्यकशास्त्रटीकाम्**।
भवे भवे तेन ममैवमेवं भूयाज्जिनोक्ते तु मते प्रयासः ॥

अन्यच्च संत्यज्य समस्तसत्त्वा मात्सर्यदुःखं भवबीजभूतम्।
सुखात्मकं मुक्तिपदावहं च सर्वत्र माध्यस्थ्यमवाप्नुवन्तु ॥ छ ॥

ग्रंथाग्रं **२२०००** ॥ श्री ॥ शुभं भवतु ॥ छ ॥ ११ ॥ संवत् १४९२ **वर्षे** आषाढ सुदि ५ गुरौ श्री**मेदपाटदेशे** श्रीदेव**कुलपाटक**पुरवरे श्री**कुंभकर्ण**राज्ये श्री**खरतर**गच्छे श्री**जिनचंद्र**सूरिपट्टे श्री**जिनसागर**सूरिराजानामुपदेशेन श्री**ऊकेश**वंशीय-**नवलक्षशाखामंडन** सा० श्री**रामदेव**भार्या साध्वानी **मेलादे** तत्पुत्र राजमंत्रिधुराधौरेयः साधु श्री**सहणपाल**स्तेन सं० **रणमल्ल** सा० **रणधीर** सा० **रणवीर** सा० **भांडा** सा० **सांडा** सा० **रणभ्रम** सा० **चउंडा** सा० **कर्मसिंह**प्रमुखसारपुत्रपरिवारपरिकलितेन निजपुण्यार्थं श्री**आवश्यकबृहद्वृत्तिद्वितीयखंडं** भांडागारे लिखापितं ॥ छ ॥ शुभमस्तु। चिरं नंद्याद्वावच्यमानं साधुवृंदैः ॥ छ ॥

परिशिष्टानि।

[१] ग्रन्थसूची—कालानुक्रमेण।

१२८७	कातन्त्रकृदुणादि	४०६
१२८७	बृहत्संग्रहणीजिनभद्रीया	२४२
१२८९	गउडवहो	४११
१२८९	रत्नचूडकथा	३७४
१२९०	प्रकरणपोथी	१३१
१२९०	,,	१९२
१२९०	धर्माभ्युदयकाव्य	३८२
१२९०	वैराग्यकुलक	१५४
१२९१	उपदेशमाला प्राकृतकथायुक्तवृत्ति	२८४
१२९२	नन्दीसूत्रादिवृत्ति	३
१२९२	योगशास्त्र	२५९
१२९२	सिद्धहेम०आदि	३९७
१२९३	,,	३९५
१२९४	आवश्यकसूत्रशिष्यहितावृत्ति	८४
१२९४	योगशास्त्र	२५४
१२९५	उपासकवृत्त्यादि	३०
१२९५	त्रिषष्टिशलाकापुरुषचरित्र	३१०
१२९६	आवश्यनिर्युक्ति	८३
१२९६	उत्तराध्ययन सुखबोधावृत्तिसह	१२४
१२९६	पाक्षिकसूत्रादि	९०
१२९७	आवश्यकहारिभद्रीवृत्तिटिप्पन	८८
१२९७	त्रिषष्टिशलाकापुरुषचरित्र	२९७
१२९८	भगवतीवृत्ति	१८
१२९८	सिद्धहैमव्याकरण	४००
१२९९	समराइच्चकहा	३५८
१३ मो	उपदेशमालादि	१८२
१३ मो आदि	महानिशीथसूत्र	६२
,,	पञ्चाशकप्रकरण	१६३
,,	प्रकरणपोथी	१८५
,,	दर्शनशुद्धि सटीक	२६७
,,	नेमिनाथचरित्र	३३८
,,	पृथ्वीचन्द्रचरित्र	३७०
१३ मो पूर्वार्ध	दशवैकालिकसूत्रादि	९७
,,	दशवैकालिकनिर्युक्ति	९७
,,	प्रशमरति	१४८
,,	प्रकरणपोथी	१६१
,,	प्रथमद्वितीयकर्मग्रन्थ प्राचीन	१६५
,,	प्रकरणपोथी	१७४

१३ मो पूवार्ध	पञ्चाशकादि	१७७
,,	प्रकरणपोथी	१८०, १८८, २०१, २२७
,,	पञ्चसंग्रहदीपक	२३०
,,	बृहत्सङ्ग्रहण्यादि	२३३
,,	धर्मरत्नप्रकरण बृहद्वृत्तिसह	२७३
,,	उपमितभवप्रपञ्चा	२९१
,,	त्रिषष्टिशलाकाचरित्र	३०९
,,	पार्श्वनाथचरित्र	३४०
,,	भुवनसुन्दरीकथा	३६२
,,	दानादिप्रकाश	३८२
,,	आख्यानकमणिकोश	३८५
,,	न्यायावतारवृत्ति	४२३
,,	बृहत्क्षेत्रसमासप्रकरण	४३८
१३ मो उत्तरार्ध	कल्पसूत्रादि	७२
,,	आवश्यकनिर्युक्ति	८३
,,	आवश्यकशिष्यहितावृत्ति द्वितीयखन्ड	८५
,,	चैत्य०वन्द०प्रत्या०प्रति०सूत्रवृत्ति	९२, ९३
,,	दशवैकालिकनिर्युक्ति	१०१
,,	उत्तराध्ययन	१०२
,,	पञ्चसूत्र	१३९
,,	प्रकरणपोथी	१४०
,,	,,	१६६
,,	कर्मविपाकप्रथमकर्मग्रन्थप्राचीन	१६८
,,	प्रकरणपोथी	२०५
,,	ध्यानशतक	२१०
,,	धर्मोपदेशमाला	२१५
,,	बृहत्सङ्ग्रणीश्रीचन्द्रीया	२४३
,,	चैत्यवन्दनभाष्य संघाचारवृत्तिसह	२४४
,,	योगशास्त्र	२५४
,,	,,	२५९
,,	,,	२६१, २६२
,,	उपदेशमाला प्राकृतकथायुक्तवृत्तिसह	२८४
,,	उपदेशमाला हेयोपादेयावृत्तिसह	२८४
,,	त्रिषष्टि०परिशिष्टपर्व	३०८
,,	त्रिषष्टिशलाकाचरित्र	३११
,,	,,	३१३
,,	अममचरित्र	३४९
,,	रत्नचूडकथा	३७४

१३ मो उत्तरार्ध	सुदर्शनाचरित्र	३७८
,,	शालिभद्रचरित्रादि	३८१
,,	उपदेशमालाकथाकोश	३९२
,,	सिद्धहेम०आदि	३९६
,,	,,	३९८
,,	,,	४०१
,,	हेमलिङ्गानुशासन	४०६
,,	अभिधानचिन्तामणिनाममाला	४०९
,,	कुट्टनीमत	४२६
,,	समयसारव्याख्या	४२९
,,	स्थानाङ्गसूत्र	४३७
,,	भगवतीसूत्र	४३८
१३ मो अंत	ज्ञातासूत्रादि	२७
,,	उत्तरा०अध्ययनो	१६१
,,	बृहत्संग्रहण्यादि	१९१
,,	वीतरागस्तोत्र	२३३
,,	पञ्चसङ्ग्रह सटीक प्रथमखण्ड	२३८
,,	प्रवचनसारोद्धारविषमपदपर्याय	२५३
,,	त्रिषष्टिशलाकाचरित्र	३००
,,	रत्नचूडकथा	३७४
,,	रघुवंशकाव्य	४११
१३००	सिद्धहेम०व्याकरण	३९९
१३०१	उपासकादि	३३
१३०१	अनुयोगादि	६५
१३०३	आचाराङ्गनिर्युक्ति	३
१३०३	आचाराङ्गचूर्णी	७
१३०६	निर्भयभीमव्यायोग	४२२
१३०७	ज्ञातासूत्रादि	२०
१३०८	उत्तराध्ययन सुखबोधावृत्तिसह	११२
१३०८	प्रकरणपोथी	१६३
१३०९	व्यवहारसूत्रनिर्युक्तिभाष्य वृत्तिसह प्र०खंड	५३
,,	,, द्वि०खंड	५४
,,	,, तृ०खंड	५५
,,	पाक्षिकसूत्र सवृत्तिक	८९
१३१४	दशवैकालिक सटीक	१०४
१३१५	कल्पसूत्रटिप्पनक	७३
१३१७	महानिशीथसूत्र	६०
१३१८	त्रिषष्टिशलाकाचरित्र	३१२

.१३१८	न्यायप्रवेशपञ्जिकादि	४२४
१३२२	विवेकमञ्जरी	२७५
१३२४	त्रिषष्टिशलाकाचरित्र	३०२
१३२५	प्रकरणपोथी	१४४
१३२६	राजप्रश्नीयादि	३६
१३२७	आचाराङ्गसूत्रादि	५
१३२७	आचाराङ्गटीका	६
१३२७	सूत्रकृताङ्गवृत्त्यादि	१०
१३२८	दशाश्रुतस्कन्धसूत्रादि	४७
,,	पञ्चकल्पमहाभाष्यादि	४८
१३३३	अनुयोगद्वारचूर्णी	६८
१३३८	शान्तिचरित्रपद्य	३३२
१३४९	सूत्रकृताङ्गादि	१२
,,	समवायाङ्गसूत्रादि	६२
१३५२	उत्तराध्ययन सुखबोधावृत्तिसह	१२०
१३६५	कल्पसूत्रादि	८०
१३७६	अभिधानचिन्तामणिनाममाला	४०९
१३८३	उपदेशमालाहेयोपादेयावृत्ति	२८२
१३८७	प्रज्ञापनावृत्तितथासूत्र	३८
१३८८	वसुदेवहिण्डी प्रथमखण्ड	३५७
१३९०	,, मध्यमखण्ड	३५८
१४ मो	आचाराङ्गसूत्र	३
,,	श्राद्धदिनकृत्य सटीक	२६३
,,	पार्श्वनाथचरित्रपद्य	३४३
,,	नागकुमारचरित्र	३९४
,,	कविशिक्षा	४१०
१४ मो आदि	आचाराङ्गटीका	४
,,	भगवतीसूत्र	१५
,,	व्यवहारचूर्णी	५२
,,	श्रावकप्रज्ञप्ति	२२६
,,	दर्शनशुद्धि सटीक	२७१
,,	शतपदीवृत्ति	३१५
,,	शान्तिनाथचरित्रपद्य	३२९
,,	धर्माभ्युदयकाव्य	३८३
,,	सिद्धहेमव्याकरण	३९८
,,	,,	३९९
,,	धर्मबिन्दु सटीक	४३०

१४ मो पूर्वार्ध	स्थानाङ्गवृत्ति	१४
,,	औपपातिकसूत्रादि	३५
,,	बृहत्कल्पचूर्णी प्रथमखण्ड	५०
,,	बृहत्कल्पचूर्ण्यादि	५१
,,	बृहत्कल्पलघुभाष्यादि	५१
,,	महानीशीथसूत्र	६०
,,	कल्पसूत्रादि	६९
,,	कल्पसूत्रचूर्ण्यादि	७३
,,	अनुयोगद्वारचूर्णी	८३
,,	आवश्यकचूर्णी प्रथमखण्ड	८३
,,	,, द्वितीयखण्ड	८४
,,	उत्तराध्ययन सुखबोधावृत्तिसह	११९
,,	प्रकरणपोथी	१४८
,,	,,	१५३
,,	,,	१५८
,,	,,	१६८, १७०, १८२, १८७, १९३, १९८, २०८, २१६, २२२
,,	ऋषिमण्डल	२१६
,,	भवभावना	२२६
,,	साधु-श्रावकसामाचारी	२२७
,,	प्रवचनसारोद्धार सटीक	२५३
,,	योगशास्त्र	२६२
,,	उपदेशमालादोघट्टीवृत्ति	२८६
,,	त्रिषष्टिशलाकाचरित्र	३०१, ३११, ३१३, ३१५
,,	मुनिसुव्रतकाव्यपद्य	३३७
,,	पाण्डवचरित्र	३७४, ३७७
,,	अष्टप्रकारीपूजाकथात्रय	३७९
,,	सिद्धहेमव्याकरण	३९७, ३९८, ३९९, ४००, ४०१
,,	सुभाषितपद्यसङ्ग्रहादि	४२१
,,	न्यायावतारसूत्रवृत्ति	४२६
,,	स्त्रीमुक्तिकेवलिभुक्ति	४२६
,,	बृहज्जातकादि	४२७
,,	उपमितभवप्रपञ्चा	४३१
१४ मो पूर्वार्ध	धर्मरत्नप्रकरण	४३४
,,	षडशीतिकर्म०	४३८
१४ मो उत्तरार्ध	जम्बूद्वीप०प्रज्ञप्तिसूत्रादि	३९
,,	कालिकाचार्यकथा	७०

[२] नामसूची।

[३] ग्रन्थसूची।

[४] ग्रन्थकारसूची।

[५] उपनामसूची।

[६] लेखकसूची।

[७] मुनिसूची।

[८] ग्रन्थकारसहायकमुनिसूची।

[९] राजसूची।

[१०] मन्त्रि-दण्डनायकसूची।

[११] राज्ञीसूची।

[१२] श्रेष्ठिसूची।

[१३] श्रेष्ठिनी-श्रेष्ठिपुत्रीसूची।

[१४] ज्ञाति-कुल-गोत्र-गच्छ-वंश-शाखासूची।

[१७] नगरादिसूची।

[१६] देशसूची।

[१७] चैत्यसूची।